





A TRIENNIAL CATALOGUE OF MANUSCRIPTS

COLLECTED
DURING THE TRIENNIUM
1934–35 TO 1936–37

FOR THE

GOVERNMENT ORIENTAL MANUSCRIPTS LIBRARY, MADRAS

BY

BHĀRATA KALĀNIDHI VIDYĀSĀGARA VIDYĀVĀCASPATI
P. P. SUBRAHMANYA SASTRI, B.A. (Oxon.), M.A. (Madras)
Ex-Curator, Government Oriental Manuscripts Library and Professor of Sanskrit and Comparative Philology Presidency College, Madras

AND

A. SANKARAN, M.A., PH.D.
Curator, Government Oriental Manuscripts Library, Madras, at Tirupati

(*Prepared under the orders of the Government of Madras*)

VOLUME IX—Sanskrit
(R. No. 5701 to R. No. 5996)

PRINTED BY THE SUPERINTENDENT
GOVERNMENT PRESS
MADRAS
1943



TABLE OF TRANSLITERATION

	Consonants.	Semi-vowels, Sibilants and Aspirate.	Vowels.	Diphthongs.
Gutturals	k, kh, g, gh, ṅ ..	h, ḥ ..	a, ā ..	e, ai.
Palatals	c, ch, j, jh, ñ ..	y, ś ..	i, ī ..	
Linguals	ṭ, ṭh, ḍ, ḍh, ṇ ..	r, ṣ	ṛ, ṝ ..	..
Dentals	t, th, d, dh, n ..	l, s	ḷ ..	..
Labials	p, ph, b, bh, m ..	v	u, ū ..	o, au.

INTRODUCTION

The ninth volume of the Triennial Catalogue of Sanskrit Mss. contains the description of mss. acquired or restored during the triennium 1934–35 to 1936–37 and is prepared on the same plan as that of the first eight volumes. The numbering of the manuscripts and the pagination of this volume are in continuation of those of the eighth volume. A subject index, an author index and a general index are prefixed to the volume.

Attention is drawn below to a few of the more important works described in this volume.

R. No. 5712. Bhaṭṭikāvya with six commentaries.

The "Bhaṭṭikāvya" is a well-known poem of the 'Mahākāvya' type in 22 sargas describing the story of Rāma as found in Vālmīki's "Rāmāyaṇa." The poem, though rich in poetic merits, is chiefly intended to give illustrations of the rules of Sanskrit Grammar. The commentators as well as most scholars identify its author, Bhaṭṭi with Bhartṛhari. However, from the available evidences, it is not possible to decide beyond doubt whether the author is identical with Bhartṛhari, the famous author of the "Vākyapadīya" and "Mahābhāṣya-dīpikā."

Besides Mallinātha, six others have commented upon this poem. It is interesting to note that each of them tries to prove that the poem is to illustrate the rules of different grammars such as the "Mugdhabodha" and "Supadma." The names of the commentators and their commentaries are as follows:—(1) "Vyākhyānanda" by Rāmacandra, son of Śrī Cakravartin. He explains the stanzas as illustrations of the rules of the 'Supadma' grammar. He quotes one Jaṭādhara, a lexicographer and Vidyāsāgara, another commentator on the poem. The commentary is simple and interesting. (2) "Bhaṭṭicandrikā" of Vidyāvinoda. He identifies the author with Bhartṛhari, son of Śrīdharasvāmin. He quotes Vidyāsāgara, the author ot another

commentary "Jayamaṅgalā", Subhūticandra, the commentator on the "Amarakośa," Devasvāmin and Goyīcandra. (3) "Bhaṭṭiṭīkā Vaijayantī" by Kandarpacakravartin. The commentator follows the 'Supadma' school of Vyākaraṇa. He identifies the author with Bhartṛhari. He quotes Vidyāsāgara and Jinendrabuddhi, the author of "Nyāsa alias Kāśikāvivaraṇapañcikā." (4) "Kalāpadīpikā" by Puṇḍarīkākṣavidyāsāgara, son of Śrīkānta. Vidyāvinoda calls this commentary 'Jayamaṅgalā' (vide No. 2 ibid). He is also the author of "Kātantrapradīpikā." He quotes Jinendrabuddhi, Vardhamāna, Devamiśra and a work "Śrīpatisūtra." He follows the "Kālāpavyākaraṇa." (5) "Mugdhabodhinī" by Bharatasena, son of Mallika. He follows the "Mugdhabodha" school of Vyākaraṇa and identifies the author with Bhartṛhari. He quotes Puruṣottama, Vopadeva and Devīdāsa. (6) "Bhaṭṭibodhinī" by Harihara. He also identifies the author with Bhartṛhari and quotes Jaṭādhara and Bāṇeśvara.

R. No. 5721. *Sūtrārthāmṛtalaharī and its commentary by Kṛṣṇāvadhūtapaṇḍita, son of Bhīmācārya.*

Kṛṣṇāvadhūtapaṇḍita was a recent author of many interesting works. About ten of his works appear in this Catalogue. The present work, Sūtrārthāmṛtalaharī is a brief one explaining the purport of the 'Brahmasūtras' according to the Dvaita school of Vedānta. In the commentary following the text he gives, for the purpose of comparative study, the views of the Advaita, Viśiṣṭādvaita and Dvaita schools on some important sūtras. He says that besides Śrī Madhva there are 21 Bhāṣyakāras on the 'Brahmasūtras,' viz.—

1 Bhāratīvijaya.
2 Saccidānanda.
3 Brahmaghoṣa.
4 Śatānanda.
5 Uddhṛta.
6 Vijaya.
7 Rudrabhaṭṭa.
8 Vāmana.
9 Yādavaprakāśa.
10 Bhartṛprapañca.
11 Dramiḍa.
12 Brahmadatta.
13 Bhāskara.
14 Piśāca.
15 Vṛttikāra.
16 Vijayabhaṭṭa.

17 Viṣṇukrānta.
18 Vādīndra.
19 Mādhavadāsa.
20 Śaṅkara.
21 Rāmānuja.

His works 'Advaitasūtrārthapaddhati' (R. No. 5727) and 'Advaitanavanīta' (R. No. 5750) are intended to represent the views of the Advaita school of Vedānta. He explains clearly in this work the Advaita principles as expounded by Vācaspati and other well-known authors. He calls himself in the colophon of the former work "श्रीमद्द्वैताद्वैतविशिष्टाद्वैतवेदान्तप्रक्रियाभिज्ञात"

His works on poetics and rhetoric, viz., "Kāvya navanīta" (R. No. 5723), "Chandonavanīta" (R. No. 5724), "Kāvyalakṣaṇasaṅgraha" (R. No. 5725) and "Camatkāracāmīkara" (R. No. 5726) are also very interesting and worth reading. From these works the author is known to be well versed in Sanskrit literature.

R. 5776. Nyāyasāravyākhyā Nyāyakalānidhi.

This is a rare and interesting commentary by Ānandānubhava on the "Nyāyasāra" of Bhāsarvajña.

R. 5777. Śrībhāṣyabhāvaprabodhana by Meghanādārisūri, son of Nāthasūri.

This is a brief commentary on Śrī Rāmānuja's "Śrībhāṣya." The author has written two other works, namely, "Nayaprakāśikā" and "Nayadyumaṇi." The "Nayaprakāśikā" is a more elaborate commentary on the "Śrībhāṣya" than this. He puts forth therein various objections raised by opponents on the "Śrībhāṣya" and refutes them ably by applying the rules of interpretation. The "Nayaprakāśikā" is one of the commentaries included in the publication of the "Śrīhbāṣya" undertaken by Paṇḍit V. Krishnamacharya of the Presidency College, Madras. The author Meghanādārisūri is said to be a descendant of Śrīrāmamiśra alias Somāśiyāṇḍān, one of Śrī Rāmānuja's disciples. He is known to be earlier than the "Tattvaṭīkā," a critical commentary on the "Śrībhāṣya" by Śrī Vedāntadeśika. The author says that the present work is a systematic commentary on the "Śrībhāṣya," while the "Nayaprakāśikā"

is a critical treatise on the same. The third work "Nayadyumaṇi" is an independent work, expounding the principles of the Viśiṣṭādvaita system of Vedānta.

R. 5778 (*a*) *Caṇḍī Rahasyam.*
R. 5778 (*b*) *Rāmāyaṇasāra Saṅgraha—Raghuvīrastavaḥ.*

Śrī Nīlakaṇṭha Dīkṣita is the author of these two hitherto unknown stotras. These have been recently published by the Sri Vani Vilas Press, Srirangam, with the help of the above-noted manuscripts.

R. 5781. *Rāmāyaṇavyākhyā by Īśvaradīkṣita.*

Īśvara Dīkṣita is the author of both the "Bṛhadvivaraṇa" and the "Laghuvivaraṇa" on the 'Rāmāyaṇa.' From D. 15890, we know that he wrote his "Bṛhadvivaraṇa" in 1517–1518 A.D., when Bukkarāya was ruling over the Karṇāṭaka country.

R. 5781 *represents his Laghuvivaraṇa.*

Of the 294 manuscripts noticed in this volume, it is a matter for satisfaction to note that as many as 241 manuscripts are presentations by the public. Sri Sarvajñā Cārya of Hospet presented 12 manuscripts (R. 5748—R. 5759); Sri K. C. Gopalan, Sub-Judge, Vizagapatam, presented 15 manuscripts (R. 5760—R. 5774); and Sri P. Veṅkaṭāramaṇācār, Triplicane, gave his entire collection of 202 manuscripts for a nominal sum.

It is hoped that the additional information in the catalogue regarding the extent of each manuscript will help scholars to estimate the copying charges of the works they are interested in. The copying charges for 1,000 granthas are Rs. 6–8–0 and the comparing charges Rs. 2–12–0 for every 1,000 granthas—a grantha being a unit of 32 syllables.

P. P. SUBRAHMAṆYA SĀSTRI,
Curator, Government Oriental Manuscripts Library.

MADRAS,
5th November 1941.

CONTENTS

ALPHABETICAL SYNOPSIS OF THE SUBJECT HEADINGS.

NOTE.—Reference is given to the pages of the Subject Index.

SUBJECT INDEX OF THE WORKS DESCRIBED IN THE SANSKRIT PART OF THE TRIENNIAL CATALOGUE OF MANUSCRIPTS—VOL. IX.



* [NOTE.—The Letters in column 2 are used with the following significance :—

C.C. = No copy of the work is noticed in the catalogus catalogorum.
D.C. = The work has not appeared in any descriptive catalogue.
C.T. = There are not more than 3 copies in the catalogus catalogorum.
L. = There were no copies in the Library.
P. = The manuscript contains a portion which was not in the Library.
T. = There were not more than 3 copies in the Library.]

Vedic Literature.

Name of the work.	R. Number.
Atharvaṇopaniṣadbhāṣyaṭīkā	D.C.L. 5887 (*f*)
Bṛhadāraṇyakabhāṣyaṭīkā	D.C.L. 5868
Bṛhadāraṇyakopaniṣat	5863 (*k*)
Bṛhadāraṇyakopaniṣadbhāṣyam	T. 5863 (*l*)
Do.	5872
Chāndogyopaniṣadarthasaṅgrahaḥ	T. 5922
Chāndogyopaniṣadbhāṣyaṭīkā-Padārthakaumudī	5930, 5947
Chāndogyopaniṣadvyākhyā	T. 5979 (*b*)
Īśāvāsyopaniṣat	5863 (*a*)
Īśāvāsyopaniṣadarthasaṅgrahaḥ	D.C.L. 5887 (*b*)
Īśāvāsyopaniṣadbhāṣyam	5863 (*b*)
Īśāvāsyopaniṣadbhāṣyaṭīkā	5828, 5887 (*a*) 5899 (*b*), 5914 (*f*)
Kāṇvopaniṣadarthasaṅgrahaḥ	D.C.L. 5979 (*a*)
Kāṭhakopaniṣat	5803 (*a*)
Kāṭhakopaniṣadbhāṣyam	5803 (*b*), 5863 (*f*)
Kāṭhkopaniṣadbhāṣyaṭīkā	D.C.L. 5887 (*g*)
Kaṭhavallyupaniṣat	5863 (*i*)
Kenopaniṣat	5955
Kṛṣṇayajurvedakāṭhakam	5768
Māṇḍūkyopaniṣat	5863 (*g*), 5967
Māṇḍūkyopaniṣadbhāṣyam	5863 (*h*), 5967
Māṇḍūkyopaniṣadbhāṣyaṭīkā	D.C.L. 5887 (*d*)
Mantrārthamañjarī	D.C.L. 5982 (*a*)
Muṇḍakopaniṣat	5959
Pañcasūktam	T. 5993 (*a*)
Praśnopaniṣat	5863 (*c*)
Praśnopaniṣadbhāṣyam	5863 (*d*)
Praśnopaniṣadbhāṣyavivaraṇam	T. 5914 (*i*)
Puruṣasūktavyākhyā	D.C.L. 5889 (*a*)
Ṛgbhāṣyam	5853, 5938 (*b*)
Ṛgbhāṣyaṭīkā	5857, 5892, 5918
Ṛgbhāṣyaṭīkāvyākhyā	D.C.L. 5982 (*b*)
Ṛksaṁhitā	5938 (*a*)

Name of the work.	R. Number.
Barhmayajñaprayogaḥ	5933 (a)
Prayogaratnamālikā	T. 5733
Samprokṣaṇavidhiḥ	T. 5935 (e)
Śrīcakrapratiṣṭhāvidhiḥ	D.C.L. 5996 (c)
Tarpaṇadarpaṇam	T. 5956
Nyāya.	
Dvitvavādārthaḥ	D.C.L. 5748
Gadādharīyakroḍapatram	5927 (c)
Gadādharīyavyākhyā	5940, 5988
Gadādharīyaṭīkā-Nyāyaratnam	T. 5869
Gadādharīyaṭippaṇam-Nyāyaratnam	T. 5888 (a)
Kārakavicāraḥ	L. 5934 (c)
Kārikāvalī	5873 (b)
Kiraṇāvalīvyākhyā	T. 5787
Muktāvalīvyākhyā-Dinakarīyā	5919 (a)
Muktāvalīvyākhyānam-Prakāśaḥ	5904
Nyāyasāravyākhyā-Nyāyakalānidhiḥ	D.C.L. 5776
Nyāyasiddhāntamañjarī	5888 (d)
Nyāyasiddhāntamañjarīdīpikā-Tarkaprakāśikā	5944
Pañcāvayavavākyalakṣaṇam	D.C.L. 5995
Prāmāṇyavādaḥ	T. 5989
Siddhāntamuktāvalī	5873 (a)
Tarkanavanītam	D.C.L. 5751
Tarkasaṅgrahavyākhyā-Dīpikā	5870 (b)
Tarkasaṅgrahavākyārthaniruktiḥ	T. 5931
Tattvacintāmaṇidīdhitiḥ	5983, 5986
Tattvacintāmaṇidīdhitiprakāśikā	5899 (a), 5919 (f) 5934 (b), 5984 5987
Tattvacintāmaṇidīdhitivyākhyā-Bhavānandīyā	5799
Tattvacintāmaṇivyākhyā-Dīdhitiḥ	5934 (a)
Tattvacintāmaṇivyākhyā-Siṁhavyāghrī	T. 5978
Vyutpattivādaḥ	5877, 5941
Vaiśeṣika.	
Padārthasaṅgrahaḥ	5939 (a) 5981 (a.b)
Padārthasaṅgrahavyākhyā	5939 (b)
Padārthadharmasaṅgrahaḥ	T. 5782 (a)
Padārthadharmasaṅgrahavyākhyā	D.C.L. 5782 (b)
Mīmāṁsā.	
Bhāṭṭadīpikā	5927 (b)
Mīmāṁsānyāyaprakāśaḥ	5927 (a)
Nyāyabinduḥ	D.C.L. 5792
Ślokavārtikavyākhyā-Nyāyaratnākaraḥ	D.C.L. 5876
Vedānta.	
Ānandarasasāgaraḥ	D.C.L. 5749
Brahmasūtram	5920 (b)
Do.	5766 (b)
Advaita.	
Advaitanavanītam	D.C.L. 5750
Advaitasārārthapaddhatiḥ	D.C.L. 5727
Brahmasūtrabhāṣyam	D.C.L. 5937 (b

Name of the work.	R. Number.
Viśiṣṭādvaita.	
Apūrvabhaṅgaḥ	C.C.T. 5744 (a)
Bhedavādaḥ	T. 5744 (c)
Dṛśyatvavicāraḥ	D.C.L. 5963
Prapañcamithyātvakhaṇḍanam	5744 (d)
Saguṇavādaḥ	D.C.L. 5744 (b)
Śrībhāṣyabhāvaprabodhanam	D.C.L. 5777
Śrībhāṣyādhikaraṇasaṅgrahaḥ	D.C.L. 5729
Vedāntadīpaḥ	5766 (a)
Viśiṣṭādvaitavijayavādaḥ	D.C.L. 5754
Vedāntakārikāvalī	5759
Vedāntaratnamālā with Alaṅkārādarśa	T. 5753
Dvaita.	
Abhinavatāṇḍavam	D.C.L. 5807, 5831
Abhinavatarkatāṇḍavam	D.C.L. 5908
Aṇubhāṣyavyākhyānam	D.C.L. 5965
Anuvyākhyānanyāyavivaraṇaṭīkā-Nyāyaprakāśikā	D.C.L. 5885
Bhagavadgītābhāṣyam	5832
Bhagavadgītābhāṣyaṭīkā-Prameyadīpikā	D.C.L. 5800, 5811 5905
Bhagavadgītātātparyanirṇayaḥ	T. 5805, 5853
Bhagavadgītātātparyanirṇayaṭīkā-Nyāyadīpikā	5925, 5929 (b)
Bhāgavatatātparyanirṇayaḥ	5818, 5878, 5917 (a)
Bhujitthetyādisūktārthaḥ	D.C.L. 5977 (b)
Bhāratatātparyanirṇayaḥ	5809
Bhedojjīvanam	T. 5821
Bhedojjīvanaṭippaṇī	T. 5822
Brahmasūtrabhāṣyam	5844, 5856 5906 5937 (b)
Brahmasūtrabhāṣyavyākhyā-dīpikā	5799, 5917 (d)
Brahmasūtrabhāṣyārthamañjarī	D.C.L. 5889 (c)
Brahmasūtrabhāṣyaṭīkā-Tattvapradīpikā	D.C.L. 5980
Brahmasūtrabhāṣyaṭīkāvivṛtiḥ-Tātparyacandrikā	T. 5896
Brahmasūtrabhāṣyaṭīkāvyākhyā-Bhāvadīpaḥ	T. 5907
Brahmasūtrabhāṣyavyākhyā-Tattvaprakāśikā	5804, 5914 (h)
Brahmasūtrasaṅgatyarthaprakāśaḥ	D.C.L. 5889 (b)
Brahmasūtrāṇubhāṣyaṭīkā	D.C.L. 5815
Brahmasūtrādhikaraṇārtharatnamālā	D.C.L. 5904
Brahmasūtrānuvyākhyānam	5843, 5881
Brahmasūtrānuvyākhyānaṭīkā-Nyāyasudhā	5847, 5855, 5875 5874 (c), 5929, 5937
Karmanirṇayaḥ	D.C.L. 5794
Laghutāratamyaṭīkā	D.C.L. 5874 (b)
Madhvavijayavyākhyā-Padārthaprakāśikā	5928
Mahābhāratatātparyanirṇayaḥ	5850, 5924
Maṇimañjarī with commentary	T. 5868
Māyāvādakhaṇḍanam	5911 (d)
Māyāvādakhaṇḍanapañcikāvyākhyā	5898 (a)
Māyāvādakhaṇḍanaṭīkā	5914 (d)

AUTHOR INDEX OF THE SANSKRIT PART OF THE TRIENNIAL CATALOGUE OF THE MANUSCRIPTS—Vol. IX.

GENERAL INDEX

A TRIENNIAL CATALOGUE OF MANUSCRIPTS.

1934-35 to 1936-1937.

VOLUME IX.

PART I—SANSKRIT—A.

R. No. 5701

Paper. 10½ × 9½ inches. Foll. 20. Lines, 20 in a page. Devanāgarī. Good. Extent, 1,700 Granthas. Not printed.

Restored in 1934–35 from D. No. 5173.

प्रमेयकण्ठिका by शान्तिवर्णः

PRAMEYAKANṬHIKĀ by Śāntivarṇa.

Foll. 1a—20s. Foll. 20b is left blank.
Contains stabakas 1—4 complete ; 5th incomplete.

R. No. 5702

Paper. 10½ × 9½ inches. Foll. 64. Lines, 20 in a page. Devanāgarī. Good. Extent, 1,600 Granthas. Printed.

Restored in 1934–35 from D. No. 2801.

स्मृतिरत्नमहोदधिः by परमानन्दघनः

SMṚTI RATNAMAHODADHIḤ by Paramānandaghana.

Foll. 1a—63a. Foll. 63b an l 64 are left blank.
Contains Âś.ucakāṇḍa complete.

R. No. 5703

Paper. 10½ × 9½ inches. Foll. 3. Lines, 20 in a page. Devanāgarī. Good. Extent, 70 Granthas. Not printed.

Restored in 1934–35 from D. No. 5409.

स्त्रीशूद्रपञ्चसंस्कारविधिः

STRĪŚŪDRAPAÑCASAṂSKĀRAVIDHIḤ.

Foll. 1a—3a. Fol. 3b and 4 are left blank.
Complete.

R. No. 5704

Paper. 10½ × 9½ inches. Foll. 10. Lines, 20 in a page. Devanāgarī. Good. Extent, 250 Granthas. Not printed.

Restored in 1934-35 from D. No. 13282.

द्रव्यवैशेषिकम्

DRAVYAVAIŚEṢIKAM.

Foll. 1a—10a. Foll. 10b is left blank.
Complete.

R. No. 5705

Paper. 10½ × 9½ inches. Foll. 110. Lines, 20 in a page. Devanāgarī. Good.
Restored in 1934-35 from D. No. 13694.

(a) जातकयोगफलग्रन्थः

JĀTAKAYOGAPHALAGRANTHAḤ.

Foll. 1a—10a. Foll. 10b is left blank. Extent, 300 Granthas. Not printed.

Incomplete.
Restored in 1934—35 from D. 2816.

स्मृत्याचारप्रायश्चित्तसंग्रहः

SMṚTYĀCĀRAPRĀYAŚCITTASAṄGRAHAḤ.

Foll. 11a—109b. Foll. 100 is left blank. Extent, 4,750 Granthas. Not printed.

Contains Ācāra and Prāyaścitta rules.

Collected together from different Smṛtis. Wants the beginning and end.

R. No. 5706

Paper. 10½ × 9½ inches. Foll. 16. Lines, 20 in a page. Devanāgarī. Good Extent, 270 Granthas. Printed.

Restored in 1934-35 from D. No. 5274.

पराङ्कुशवैभवम् ।

PARĀṄKUŚAVAIBHAVAM.

Foll. 1a—14a. Foll. 14b, and 16 are left blank.
Incomplete.

R. No. 5707

Paper. 10¼ × 9½ inches. Foll. 4. Lines, 20 in a page. Devanāgarī. Good. Extent, 80 Granthas. Not printed.

Restored in 1934–35 from D. No. 13102.

अक्षिरोगनिर्मूलनम्

AKṢIROGANIRMŪLANAM.

Complete.

R. No. 5708

Paper. 10¼ × 9½ inches. Foll. 64. Lines, 20 in a page. Devanāgarī. Good. Extent, 1,440 Granthas. Not printed.

Restored in 1934–35. Complete from D. No. 12010.

चाटुधारा

CĀṬUDHĀRĀ.

Incomplete.

R. No. 5709

Paper. 10¼ × 9½ inches. Foll. 82. Lines, 20 in a page. Devanāgarī. Good. Extent, 2,430 Granthas. Not printed.

Restored in 1934–35 from R. No. 5239.

वरवरमुनिचम्पूः by वकुलाभरणसूरिः

VARAVARAMUNICAMPŪḤ by Vakulābharaṇasūri.

Foll. 1*a*—82*a*. Foll. 82*b* is left blank.

Complete.

R. No. 5710

Paper. 10¼ × 9½ inches. Foll. 28. Lines, 20 in a page. Devanāgarī. Good. Extent, 700 Granthas. Not printed.

Transcribed in 1934–35 from a MS. available from the India Office Library.

भट्टिकाव्यस्थूलव्याख्या—सारः

BHAṬṬIKĀVYASTHŪLAVYĀKHYĀ—Sāraḥ.

Foll. 1*a*—26*a*. Foll. 26*b*—28 are left blank.

A commentary on the well-known *Bhaṭṭikāvya*.

Complete.

Beginning :

अथाशेषविशेषेणबालान्व्युत्पिपादयिषुः श्रीमर्तृहरिकृतस्य रामायणानुयायिभट्टयाख्यग्रन्थस्य विषयसंख्याच्छन्दसां प्रकाशेन तद्ग्रन्थस्य व्याख्यायां कस्यचिज्जनवरस्यातिशयानुरागस्तमजनि ।

अनन्तरंच तदभिप्रायविदा केनचिद्विप्रेण तदादिष्टेनच तद्ग्रन्थस्य व्याख्यासंपर्केणव्याख्या साराभिधो ग्रन्थस्समकारि ।

अत्रप्रथमं रुचिराच्छन्दसा अभून्नृपइत्यादिना श्रीरामचन्द्रस्य पितृत्वेनाभिमतोदशरथइतिनाम्नाख्यातो राजा आसीदित्युपवर्णनम् ।

End :

पुष्पिताग्राछन्दसा इदमधिगतेत्यादिना, अनुष्टुप्छन्दसा व्याख्यानेत्यादिना, आर्याच्छन्दसा काव्यमित्यादिना, अनुष्टुप्छतादीपतुल्येत्यादिना, ग्रन्थकर्त्रा छलेनग्रन्थस्यप्रशंसाकरणम् .

Colophon :

इति द्वाविंशतितमसर्गस्यव्याख्या ॥
समाप्तेयं भट्टिकाव्यस्यस्थूलव्याख्या ॥

R. No. **5711**

Paper. 10¼ × 9¼ inches. Foll. 90. Lines, 20 in a page. Devanāgarī. Good. Extent, 2,655 Granthas. Not printed.

Restored in 1934-35 from R. No. 3617(*c*).

मन्त्रपद्धतिः

MANTRAPADDHATIḤ.

Foll. 1*a*—89*a*. Foll. 89*b*–90 are left blank.
Complete.

R. No. **5712**

Paper. 10¼ × 9¼ inches. Foll. 502. Lines, 20 in a page. Devanāgarī. Good. Extent, 13,800 Granthas. Not printed. Bound in three Volumes.

Transcribed in 1935-36 from a MS. available from the India Office Library.

भट्टिकाव्यम्—व्याख्याषट्कोपेतम्

BHAṬṬIKĀVYAM—VYĀKHYĀṢAṬKOPETAM.

The *Bhaṭṭikāvya* with six commentaries, viz. (1) a commentary by Rāmacandraśarma, (2) Bhaṭhicandrikā by Vidyāvinoda, (3) a commentary by Kandarpaśarman, (4) a commentary by Puṇḍarīkākṣa, (5) Mugdhabodhinī by Bharata and (6) Bhaṭṭibodhinī by Hariharācārya.

Contains from the first sarga to the end of 92 stanza of the 5th sarga.

Beginning of the Text.

अभून्नृपोविबुधसखः परन्तपः
श्रुतान्वितो दशरथइत्युदाहृतः ।
गुणैर्वरंभुवनहितच्छलेन यं
सनातनः पितरमुपागमत्स्वयम् ॥

Beginning of the commentary, Vyākhyānanda, by *Ramacandra*.

नत्वाश्रीनयनानन्दचक्रवर्तिपदाम्बुजम् ।
व्याख्यानन्दोमयाग्रन्थस्तन्यतेयत्प्रसादतः ॥
वारेन्द्रवंशसंभूतश्रीरामचन्द्रशर्मणा ।
तन्यतेभट्टिकाव्यस्य टीकेयं स्वानुकारिणी ॥
सौपद्यका नवं मूलं शिष्यान्बोधयितुंमया ।
रचिताबन्धशोयत्नात्सुधीभिर्दृश्यतामियम् ॥

• • •

महाकाव्यस्यादौ आशीर्नमस्कारोवस्तुनिर्देशोवा कर्तव्य इति संप्रदायानुरोधाद्वस्तुनिर्देशंकुर्वन्निष्टदेवतास्मरणात्मकं मङ्गलमादावाविष्करोति -अभूदित्यादि दशरथ इत्युदाहृतो राजाभूत् ।

Beginning of the commentary, Bhaṭṭicandrikā by *Vidyāvinoda*.

वन्दे दूर्वादलश्यामं रामं राजीवलोचनम् ।
जानकीलक्ष्मणोपेतं भक्ताभीष्टफलप्रदम् ॥
नत्वा तातपदद्वन्द्वं ज्ञात्वा ग्रन्थकृदाशयम् ।
विद्याविनोदः कुरुते टीकां श्रीभट्टिचन्द्रिकाम् ॥
यस्य रामं घनश्यामं कृपारामं सुखेन सा ।
कौसल्या सुषुवेसूनुं स्वर्गत्यादिः प्रकाश्यत(ते) ॥

अत्रकविना श्रीधरस्वामिसूनुना भर्तृहरिणा सर्गबन्धो महाकाव्यलक्षणसूचनाय काण्डबद्धश्चकाव्यलक्षणसूचनाय कृतः। अत्र प्रकीर्णाधिकारप्रसन्नतिङन्ताश्चत्वारि। तल्लक्षणंद्विविधं, शब्दलक्षणकाव्यलक्षणभेदात्। तत्रप्रकीर्णाधिकारतिङन्तकाण्डैः शब्दलक्षणम् प्रसन्नकाण्डे(न)च काव्यलक्षणम्।

Beginning of the commentary of Kandarpaśarma.

बालं पुराणपुरुषं व्रजकुलरमणीमनोभवानन्दम्।
सजलजलदश्यामं कामं रामं श्रीनन्दनन्दनंवन्दे॥
नत्वागौरीनाथपादारविन्दं ज्ञात्वा भावंपद्मनाभस्य सम्यक्।
सौपद्मानां प्रीतयेभट्टिकाव्ये चक्रे टीकां धरिकन्दर्पशर्मा।

अत्यन्तदुर्गमतमे किल भट्टिकाव्ये
हास्याय केवलमसौखलुमेप्रसक्तिः॥
किन्त्वेकमास्तिशरणंसुहृदोऽनसूया
दोषास्पृशो गुणलवग्राहिणोहितन्तः॥
विद्यासागरटीकायां कातन्त्रप्रक्रिया यतः।
सुपद्मप्राक्रिया तस्मात्तस्मादेव प्रणीयते॥

अत्रतावन्महामहोपाध्यायभर्तृहरिकाविना शब्दकाव्ययोर्लक्षणलक्षितानि महाकाव्यतयाभिधेयानि। अतः सर्गबन्धः काण्डबद्धश्चकृतः। तत्रकाण्डानि प्रकीर्णाधिकारप्रसन्नतिङन्ताख्यानि चत्वारि। तेषुप्रसन्नंविना त्रिषुशब्दलक्षण लक्षितानि, प्रसन्नकाण्डेतु काव्यलक्षणलक्षितानि।

* * * *

Beginning of the commentary of *Puṇḍarīkākṣa*.

नत्वा शंकरचरणं ज्ञात्वा सकलंकलापतत्त्वश्च।
दृष्ट्वा पाणिनितन्त्रं वदति श्रीपुण्डरीकाक्षः॥
पाणिनिप्रक्रियायां मे प्रसिद्धत्वान्नकौतुकम्।
कलापप्रक्रिया तस्मादप्रसिद्धात्रकथ्यते॥
ध्वनिबद्धतमस्तोममपहरत्तामियं मया।
कलापदीपिका चक्रे सत्पथालोकनायच॥

अत्रकविनासर्गबन्धो लक्षणसूचनाय काव्यबद्धश्चलक्षणसूचनायकृतः

तत्रप्रकीर्णाधिकारे प्रसन्नतिङन्तकाण्डानि चत्वारि ।
लक्षणमपि द्विविधं, शब्दलक्षणकाव्यलक्षणभेदात् ।
अत्रप्रसन्नकाण्डातिरिक्तैः त्रिभिः काण्डैः शब्दलक्षणम् ।

* * * *

The commentary of *Bharata*.

Same work as that described under D. No. 11617.

But that MS. contains only first 26 stanzas of the first sarga with this commentary.

This MS. contains this commentary on all stanzas.

Beginning of the commentary of Hariharācārya.

नत्वा रामपदद्वन्द्वमरिविन्दमवच्छिदम् ।
द्विजोहरिहराचार्यः कुरुते भट्टिबोधिनीम् ॥

पूर्वग्रामिकुले कलानिधिनिभं कृत्वासुमेरुस्थितो
भ्राता तस्य जटाधरो द्विजवरो बाणेश्वरस्तत्सुतः ।

प्रायोद्विमत्सरधियः कवयः पृथिव्यां
सन्तिकुचित् क्वचिदपिप्रियसाधुवादाः ।

एकंप्रिया प्रणतिकर्म करोमि नित्यम्
मध्येद्वयोः परमदेवप्रदत्तमेव ॥

अधिगतापाणिनिमुनिकृतलक्षणलक्षणेपिसतिलक्षणेपि नानाविधसन्देहं निरस्यन्नुदाहर्तुमनाः करोति, परिवृदयन् भर्तृहरिः काव्यप्रसङ्गेनसमस्तव्याकरणार्थं दर्शयन्रामकथयैव मङ्गलंसंपादयन्काव्यमिदमारब्धवान् । अत्र-लक्षणं व्याकरणधातुमूलकत्वात्सकलपदानां प्रथममेवाभिधास्यामीति. सत्ता-मपिचिकीर्षायां भवतः क्रियासामान्यवाचित्वादाह । अभूदित्यादि ॥

* * * *

Colophon :

इति श्रीरामचन्द्रेण व्याख्यानन्दो (वि) निर्मितः ।
विवेकत्वंगतस्सर्ग प्रथमोद्दश्यतां बुधैः ॥

* * * *

Colophon :

इति विद्याविनोदकृतायां भट्टिचन्द्रिकायां प्रथमस्सर्गः ॥

Colophon :

इतिकन्दर्पचक्रवर्तिकृतायां भट्टिटीकायां प्रथमस्सर्गः ॥

* * * *

Colophon :

इति महामहोपाध्यायश्रीमच्छ्रीकान्तपण्डितात्मजश्रीपुण्डरीकाक्षविद्यासागरभट्टाचार्यकृतायां भट्टिटीकायां, प्रकीर्णकाण्डे रामसंभवः प्रथमस्सर्गः ॥

* * * *

Colophon :

इति श्रीभरतसेनकृतायां भट्टिटिकायां मुग्धबोधिन्यां प्रकीर्णकाण्डे श्रीरामसंभवोनाम प्रथमस्सर्गः ॥

* * * *

Colophon :

इति हरिहराचार्यकृतायां भट्टिबोधिन्यां टीकायां श्रीविश्वामित्रागमनं नामप्रथमस्सर्गः ॥

R. No. 5713

Paper. 10½ × 9¼ inches. Foll. 33. Lines, 20 in a page. Devanāgarī. Good. Extent, 950 Granthas.

Restored in 1935-36 from R. No. 438.

श्वेताश्वतरोपनिषत्प्रकाशिका by रङ्गरामानुज

ŚVETĀŚVATAROPANIṢATPRAKĀŚIKĀ by Raṅgarāmānuja. Complete.

R. No. 5714

Paper. 10½ × 9¼ inches. Foll. 260. Lines, 20 in a page. Devanāgarī. Good. Extent, 7,200 Granthas. Not printed.

Transcribed in 1935-36 from a MS. available from the India Office Library.

भट्टिकाव्यम्—व्याख्यापञ्चकोपेतम्.

BHAṬṬIKĀVYAM—VYĀKHYĀPAÑCAKOPETAM.

Same work as the above.

Contains sargas 16 to 22 complete.

R. No. 5715

Paper. 10¼ × 9¼ inches. Foll. 182. Lines, 20 in a page. Devanāgarī. Good. Extent, 4,550 Granthas. Not printed.

Transcribed in 1935-36 from a MS. available from the India Office Library.

भट्टिकाव्यम्—व्याख्याषट्कोपेतम्.

BHAṬṬIKĀVYAM—VYĀKHYĀṢAṬKOPETAM.

Foll. 1a—182b. Foll. 6a is left blank.

Same work as the above.

Contains from the 93rd stanza of the 5th sarga to the end of the 6th sarga.

The commentary of Ramacandra breaks off in 20th stanza of the 6th sarga.

End of the commentary of Ramacandra.

हेलक्ष्मण यदि स किञ्चित्कोपकारणमाख्यत्, कथितवती तदाचक्ष्व। ख्याप्रकथने चक्षिङः स्थाने ख्याञ्यादेशेवा आङ्पूर्वः लुङ्दीपसृशास्त्यादिनाङ्, आतो लुगित्याकारलोपः। अन्यत्रचक्षिङोलोट्सः। हेलक्ष्मण दोषेऽज्ञाते कथंतत्प्रतिसमाधानं, तदपवर्जनार्थंकर्मास्माभिः क्रियताम्। अत्रापिप्रार्थनेलोट् कर्मणितां यक्क्ङिते विलोड्यकोरिति कृधातोरान्तर्यादेशः विभादेशातहस्वस्य दीर्घोऽकृत्सार्वधातुक इति दीर्घोनस्यान्। अधिकं कातन्त्रे प्रपञ्चितम्।

R. No. 5716

Paper. $10\frac{1}{4} \times 9\frac{1}{4}$ inches. Foll. 110. Lines, 20 in a page. Devanāgarī. Good. Extent, 2,750 Granthas. Not printed.

Transcribed in 1935–36 from a MS. available from the India Office Library.

भट्टिकाव्यम्—व्याख्यापञ्चकोपेतम्.

BHAṬṬIKĀVYAM—VYĀKHYĀPAÑCAKOPETAM.

Foll. 1*a*—110*b*. Pages 1368 to 1586.
Same work as the above.
Contains 7th sarga complete.

R. No. 5717

Paper. $10\frac{1}{4} \times 9\frac{1}{4}$ inches. Foll. 311. Lines, 20 in a page. Devanāgarī. Good. Extent, 7,800 Granthas. Not printed. Bound in two volumes.

Transcribed in 1935–36 from a MS. available from the India Office Library.

भट्टिकाव्यम्—व्याख्यापञ्चकोपेतम्.

BHAṬṬIKĀVYAM—VYĀKHYĀPAÑCAKOPETAM.

Foll. 1a—156*b*. Pages from 1587 to 2208.
Same work as the above.
Contains sargas 8 and 9 complete, 10 incomplete.

R. No. 5718

Paper. $10\frac{1}{4} \times 9\frac{1}{4}$ inches. Foll. 290. Lines, 20 in a page. Devanāgarī. Good. Extent, 7,250 Granthas. Not printed. Bound in two volumes.

Transcribed in 1935–36 from a MS. available from the India Office Library.

भट्टिकाव्यम्—व्याख्यापञ्चकोपेतम्.

BHAṬṬIKĀVYAM—VYĀKHYĀPAÑCAKOPETAM.

Foll. 1*a*—290*a*. 290*b* is left blank. Pages 1 to 580.
Same work as the above.

Contains sargas 13 to 15 complete.

End of the commentary of Hariharācārya.

नृपतिमातिः राममातिः संपन्नेच्छेव हर्षान्, अरंस्त रमतेस्म। रमुक्रीडायां, लुङ् त। रजनिचरपतीनां रावणेन्द्रजिदादीनां सन्ततः अविच्छिन्नः शोक अप्यायिवर्धनेस्म। ओप्यायिवृद्धौ। दीप्य लुङ्त, तङ्, दीपजनबुधपूरितायीप्यायिभ्यांवेति इण्।

Colophon :

इति श्रीहरिहराचार्यकृतायां भट्टिटीकायां मनोहराख्यायां पञ्चदशस्सर्गः

* * * *

End of the commentary of *Kandarpacakravarti.*

नृपतेमतिः, श्रीराममतिः हर्षात् प्राप्तकामेवारंस्त, रमतेस्म। रमुक्रीडायां, लुङ्तः। रजनिचरपतीनां रावणादीनां सन्ततः निरंतरं शोकः अप्यायि, वर्धतेस्म।। ओप्यायिवृद्धौ।

Colophon :

इति कन्दर्पचक्रवर्तिकृतायां भट्टिटीकायां लुङ्विलसितो नाम पञ्चदशस्सर्गः

* * * *

End of the commentary of Puṇḍarīkākṣa.

नृपतेः रामस्य मतिः प्राप्तकामेव शत्रुवधं सीतां च प्राप्तवतीव हर्षात् रमतेस्म। रमुक्रीडायाम्। रजनिचरपतीनां, रावणेन्द्रजिदादीनां सन्ततः अविच्छन्नः शोकः वर्धतेस्म। तायृसन्तानपालनयोः। अप्यायीति पाठे-प्यायीवृद्धौ। योगविभागात् दीपजने त्यादिनाचकर्तरि इण्।

Colophon :

इति महामहोपाध्याय श्रीपुण्डरीकाक्षकृतायां भट्टिटीकायां कलापदीपिकाख्यायां लुङ्विलासितोनाम द्वितीयपरिच्छेदः। काव्यस्य (कुम्भ) कर्णवधोनाम पञ्चदशस्सर्गः॥

* * * *

End of the commentary of Bharatasēna.

नृपतेः, रामस्य मतिः प्राप्ताकामेव शत्रवधं सीतां च प्राप्तवतीव हर्षात् रमतेस्म। रमुक्रीडायाम्। रजनिचरपतीनां रावणेन्द्रजिदादीनां सन्ततः अविच्छिन्नश्शोकः वर्धतेस्म। तायृसन्तानपालनयोः। पदस्तनीणृधे...... आदिना पाक्षिकइण् अप्यायीति पाठे ओप्यायिवृद्धौ

Colophon :

इति हरिहर(भा)नुवंशसंभूतगौराङ्गमल्लिकात्मजश्रीभरतसेनकृतायां मुग्ध-बोधिन्यां भट्टिटीकायां तिङन्तकाण्डे लुङ्विलसितोनामद्वितीयः परिच्छेदः। काव्यस्य कुम्भकर्णवधोनामपञ्चदशस्सर्गः।

* * * *

End of the commentary of Vidyāvinoda.

नृपतिमतिः श्रीराममतिः हर्षात् आप्तकामैवारंस्त, रमतेस्म। रमु-क्रीडायां, लुङ्, त, लुङ् सङ्चेतिसलुङ्, अपदान्तेत्यादिनाऽनुस्वारः। रज-निचरपत्नीनां रावणादीनां सन्ततश्शोकः अप्यायि वर्धतेस्म ओप्यायिवृद्धौ। लुङ्त, सङ् दीपजनेत्यादिना इण्.

Colophon :

इति विद्याविनोदाचार्यकृतायां भट्टिटीकायां तिङन्तकाण्डे लुङविलसितोनाम-पञ्चदशस्सर्गः

R. No. 5719

Paper. 10½ × 9½ inches. Foll. 98. Lines, 20 in a page. Devanāgarī. Good. Extent, 2,450 Granthas. Not printed.

Transcribed in 1935-36 from a MS. of Śrī K. Dēśikācārya.

दिव्यसुमनोगुणवैजयन्ती by श्रीनिवासः

DIVYASUMANOGUṆAVAIJAYANTĪ BY ŚRĪNIVĀSA.

Foll. 1a-96a. Foll. 96b, 97 and 98 are left blank.

A work, in the *Campu* style, embodying the accounts of certain *Śrī* Vaisnava Ācaryas.

By Śrīnivāsa, son of Veṅkaṭadīkṣita.

Contains 7 stabakās, complete and 8th stabaka incomplete.

Beginning :

श्रीकौस्तुभो विजयतामतिशेषशिरोमणिः।
ज(द) म्पत्योः . . . . . . यः क्रीडामुकुरायते॥
तस्यसेनापतेश्शिक्षारक्षा विजयतां सदा।
विन्यस्य मोदते भारं यस्मिन्न्यस्तभरे परः॥
पराङ्कुशघनस्तृष्णांहन्तु मे चातकास्थितेः।

यदुक्ति— . . . . . . ऽत्यमभवद्वसुधातले ॥
नाथो बोधयतु क्षिप्रं हंसो मानसपङ्कजम् ॥
द्राविडीब्रह्मविद्या सा येननष्टोद्धृतापुनः ॥

प्रपद्ये पुण्डरीकाक्षं करुणामृतवारिधिम् ।
यो दर्शयामास सतां सद्वृत्तिमनृणां नृणाम् ॥
राममिश्रेगुणारामे रमणीये रमे सदा ।
रमया रमते रामो यस्य हृत्पङ्कजे शुभे ॥

* * * *

द्राक्षारसप्रणयितामनुरञ्जयन्ती
गद्यानवद्यमृदुपद्यगणैर्जयन्तीम् ।
कासारमुख्यसुमनोगुणवैजयन्ती
तन्वे सुपष्टतर . . . . वैजयन्तीम् ॥
मुरलीविनोदिमुरवैरिमोहनां
. . . . चकार चारितंमनो मम ॥
अययामुनोक्तसरणीमनुस्मर-
न्नधुना भवामि सरलीभवन्मनाः

Colophon :

इति श्रीसमानपदवाक्ययोजनामागस्याप्यसमान पदवाक्ययोजनामागस्य, प्रथमप्रयोगानुष्ठितप्रवर्ग्यस्यापि चरमैकप्रयोगानुष्ठितप्रवर्ग्यस्य सदीक्षितस्य वेङ्कट दीक्षितस्य तनयेन स्वरुपसमुचितनयेन श्रीनिवासदासेनविरचितायां दिव्य-सुमनोगणवैजयन्त्यां द्वितीयस्तबकः

End :

(चू) तदनुतत्पुत्रवरदाचार्यो रामानुजार्यसिद्धान्तविजयध्वजइति प्रख्यात-बिरुदनामधेयः काहलधवलशङ्खादि वाद्यविशेषैस्सह.

R. No. 5720

Paper. 10¼ × 9¼ inches. Foll. 189. Lines, 20 in a page. Devanāgarī. Good. Extent, 4,725 Granthas. Not printed.

Transcribed in 1935-36 from a MS. of Śrī Sarvajñācarya of Hospet.

चिदम्बरगुरुमहात्म्यम्

CIDAMBARA [GURU] MĀHĀTMYAM.

Foll. 2a—189a. Foll. 1 and 189b are left blank.

Same work as that described under R. No. 2370.

Complete.

This manuscript is said to have been copied by Traivikramādhvari in Śaka 1804 corresponding to 1882 A.D.

श्रीमन्नृपशालिवाहनशके युगेखेवासवान्जच ।
चित्रभानुसितेपक्षे मासे आषाढसंज्ञके ॥

दशम्यामिन्दुवारे स्वात्यां प्रथमप्रहरेचहि ।
एताहशशुभेदिवसे माहात्म्यं चिदम्बरस्यच ।
दूर्वोपल्यधिपेनैव त्रैविक्रमाध्वरेणच ॥

संपूर्णंलिखितं तेन सर्वलोकहितायच ।
एतच्चलिखितं मन्दमतिना पुस्तकं मया ।
यदि शुद्धमशुद्धंवा क्षम्यतां पण्डितोत्तमाः ।
स्थूलपर्यां कार्यवाशान्निवसन् श्रीसन्निधानेपि ।
तैलाद्रक्षेज्जलाद्रक्षेद्रक्षेच्छीतलबन्धनात् ।
मूर्खहस्ते नदातव्यमेवं वदति पुस्तकम् ।
एतौशङ्खकपालभूषितकरौ मालास्थिमालाधरौ
देवै द्वारवतीश्मशाननिलयौ नागारिगोवाहनौ ।
द्वित्र्यक्षौ बलिदक्षयज्ञमथनौ श्रीशैलजावल्लभौ
पापं मे हरतां सदाहरिहरौ श्रीवत्सगङ्गाधरौ ॥

चिदम्बर नमस्तेऽस्तु चिन्तितार्थप्रदायिने ।
औदुम्बरसदावास चिदम्बरनमोऽस्तुते ॥

R. No. 5721

Paper. 10½ × 9½ inches. Foll. 369. Lines, 20 in a page. Devanāgarī. Good.

Transcribed in 1935–36 from a MS. of Mr. Sarvajñācārya of Hospet.

(a) सूत्रार्थामृतलहरी by कृष्णावधूतः

SŪTRĀRTHĀMṚTALAHARĪ by Kṛṣṇāvadhūta.

Foll. 2a—58b. Foll. 1 is left blank. Extent, 1585 granthas. Not printed.

A brief statement of the purport of the *Brahmasūtras*.

Beginning :

श्रीकृष्णाय नमश्चिदात्मवपुषे राधामनोमुपुषे
विभ्राजन्नवनीतगोकुलमुषे गोपाङ्गनाह्न्मुषे ।
भक्तानां बहुवारपूरितवृषे माराधिकश्रीजुषे
लोकाडम्बरजारचोरविदुषे कंसद्विषे श्रीजुषे ॥
विज्ञाता शुकविख्यातोऽवधूतः कृष्णनाममाक् ।
यस्य पुत्रस्समव्याख भूयाद्द्यासः पिताच मे ।
श्रीमदानन्दतीर्थार्यचरणाम्भोजनिस्सृता ।
स्नपयत्वाखिलाङ्गमां करुणारसधोरणी ॥
सूत्रर्थामृतलहरी
कृष्णावधूतास्समासतः प्रसृता ।
सत्राजिद्भूजानेः
पद्यभिषिक्तातनोति तत्प्रीतिम् ॥

End :

ओं अनावृत्तिश्शब्दादनावृत्तिश्शब्दादित्येकादशेऽनावृत्त्यधिकरणे परं ब्रह्मप्राप्तस्य मुक्तस्य भोगान् भुञ्जानस्य पुनरावृत्त्यभावसमर्थनमिति मङ्गलम् ।

भस्मावशेषिताघाय भस्माभिख्यमदाच्छिदे ।
अस्माकमिष्टगुरवे ध्यस्मारव्याधये नमः ॥

कृष्णावधूतसंभूता तृष्णाच्छेदकरी कृतिः ।
कृष्णात्मेशार्पणा स्वाद्या पुष्णातु सुधियांमुदम् ॥

अस्यफलश्रुतिः । ब्रह्माण्डपुराणे श्रवणफलतारतम्यविचारे नारदाम्बरीषसंवादे, नारदः—

व्यासोक्तब्रह्मसूत्राणां सकृदावर्तनान्नृप ।
गायत्र्यास्सर्ववेदानां सहस्रावृत्तिपुण्यभाक् ॥
अर्थतात्पर्यसहितं सूत्रपाठं पठन् द्विजः
दशसाहस्रगायत्री जपपुण्यफलं लभेत् ॥
सम्भवे त्सिद्धसंकल्पः परत्राप्यत्र किंपुनः । इति ।
पूर्णप्रज्ञकृतं भाष्यं सूत्राणां प्रपठन् कली ।
कृतादिषु तपोयज्ञदानाद्यैर्यत्फलं लभेत् ॥
सर्वान्कामानिहावाप्य मुक्तोऽप्यभीष्टं समश्नुते ।
इति श्रीभविष्योत्तरपुराणे ।

Colophon :

इति श्रीकृष्णावधूतपण्डितकृतौ सूत्रार्थामृतलहर्यां संक्षेपेण तात्पर्यानुवादरूपकव्याविभागे चतुर्थाध्यायस्य चतुर्थः पादः

(b) सूत्रार्थामृतलहरीव्याख्या by कृष्णावधूतः

SŪTRĀRTHĀMṚTALAHARĪVYĀKHYĀ by Kṛṣṇāvadhūta.

Foll. 59a—359b. Extent, 7,800 granthas. Not printed.

A commentary on the above, according to each of the three schools of Hindu Philosophy, *Advaita*, *Viśiṣṭādvaita* and *Dvaita*.

Incomplete, breaks off in the 3rd pāda of the third Adhyāya and contains a portion of the first pāda of the fourth Adhyāya.

Beginning :

प्रशस्तव्यस्तवेदार्थं हस्तविन्यस्तपुस्तकम् ।
अस्तीकृततमस्तोमं निस्तुलं वस्तु संस्तुमः ॥
सूत्रार्थामृतलहरीव्याख्यामपि करोम्यहम् ।
स्वयं शिष्यस्फुटत्वार्थं प्रीणयन्बादरायणम् ॥

मङ्गलयेति । ? श्रीकृष्णायेति । राधायाः मनोभुवं, कामं पुष्णातीति, राधामनोभूड्रुषे । श्रीजुषे, लक्ष्मीप्रियाय, आशुकविरितिख्यातश्शुकइति विख्यातश्च । कृष्णनामभाक् अवधूतः कृष्णावधूतः कृष्णनामभजनकर्ता च । विरक्तश्चव्यासः, वेदव्यासः, पिता, भीमाचार्यः

Colophon :

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यप्रणीतवेदान्तप्रक्रियासर्वस्वालोडन-निष्णातस्य कृष्णावधूतस्य कृतौ ब्रह्ममीमांसाप्रक्रियोपन्यासरूपायां न्यायविवरणाद्यनेकग्रन्थसारसङ्ग्रहे सूत्रार्थामृतलहर्यां अर्थविवरणानुवादे तृतीयाध्यायस्य द्वितीयः पादः।

End :

ताह प्रायेणाधिकरणानन्तरमेवास्य विन्यासोयुक्त इति चेन्न। जिज्ञासूनामासनादिनियमस्य चित्तविक्षेपनिराकरणत्वेन तत्सहकृतध्यानस्य ज्ञानजनकत्वम्। ज्ञानिनान्तु न तथा। चित्तविक्षेपाभावादिति विशेष-प्रदर्शनार्थं तत्पूर्वमेव विन्यासस्य युक्तत्वात्। आसनं विषयः। सर्वथा-पेक्षितं नवेति सन्देहः। उभयविधसाधनदर्शनम्।

* * * *

R. No. 5722.

Paper. 10¾ × 9¼ inches. Foll. 13. Lines, 20 in a page. Devanāgarī. Good. Extent, 325 Granthas. Not printed.

Transcribed in 1935-36 from a MS. obtained on loan from Śrī Sarvajñācārya of Hospet.

लघुरामायणम् by कृष्णावधूतः

LAGHURĀMĀYAṆAM by Kṛṣṇāvadhūta.

Foll. 1a, 13a. Foll. 13b is left blank.

A poem, in an easy style, embodying the story of the *Rāmāyaṇa*.

Complete—6 kāṇḍās in 6 sargas.

Beginning :

नमो नारायणायेति नमोवाकं वदामहे।
येनानिष्टतमो धूत्वा प्राप्नुवन्त्यमृतश्रियम्॥
ब्रह्माण्डान्तच्छदे विष्णोः शयानस्य वटच्छदे।
नाभौ पद्ममभूल्लोका यस्यनाले चतुर्दश॥
तस्मिन् पद्मे विधिर्जज्ञे स्रष्टा लोकपितामहः।
महाब्रह्मोदभूत्तस्मान्मरीचिस्तनयो ऋषिः।
मरीचेः काश्यपो जातो मारीचादर्यमाभवत्।
मार्ताण्डैवस्वतो नाम मनुर्मानवशास्त्रकृत्।

वैवस्वतादभूत्पुत्र इक्ष्वाकुर्नाम पार्थिवः ।
तस्यवंशे दशरथः साधुधर्मा भवन्नृपः ।
कौसल्या कैकयी तस्य सुमित्रेतिगृहाः (स्त्रयः) ।
सु पुत्रीयन् स पुत्रेष्टि सपत्नीकश्चकारह ।

* * * *

Colophon :

इति श्रीकृष्णावधूतकवीश्वरविरचिते रामायणसारसङ्ग्रहे लघुरामायणे रामाङ्के बालकाण्डस्समाप्तः ॥

End :

मदर्थे शोकहीनाङ्गयास्तस्याः पाणिग्रहं कुरु ।
इत्युक्तस्तोऽब्रवीत्सीतां कृष्णत्वेन वृणोमि तम् ॥
ततोऽभिषिच्य लङ्कायां विभीषणमरिन्दमः ।
आरुह्यपुष्पकं सर्वैस्साकं साकेतमाययौ ।
प्रकृतिभिरथ पौरैः पद्मपंतीभसेनैः
भरित उपगतस्सन् रामचन्द्रं प्रपूज्य ।
अखिल पुर पुरन्ध्रोनत्रनीराजनाङ्गं
निजगृहमनयद्राग्हृष्टपुष्टाङ्गयष्टिः ॥

Colophon :

इति कृष्णावधूतकवीश्वरविरचिते श्रीलघुरामायणाभिधे काव्ये रामाङ्के युद्धकाण्डार्थनिरुपणं नाम षष्ठस्सर्गः ।

R. No. 5723

Paper. $10\frac{1}{2} \times 9\frac{1}{2}$ inches. Foll. 9. Lines, 20 in a page. Devanāgarī. Good. Extent, 200 Granthas. Not printed.

Transcribed in 1935–36 from a MS. obtained on loan from Śrī Sarvajñācārya of Hospet.

काव्यनवनीतम् by कृष्णावधूतपण्डितः

KĀVYANAVANĪTAM by Kṛṣṇāvadhūtapaṇḍita.

Foll. 1a—8a. Fol. 8b-9 are left blank.

A treatise on Sanskrit Rhetoric.

Complete 5 Golakās, but wants beginning.

Beginning :

. . . . . तीयोत्तरगुणनाश्यो। चतुर्थक्षणवृत्तिध्वंसप्रतियोगित्वंक्षणिकत्वम्। स्वभावसामानाधिकरण्यमव्याप्यवृत्तित्वम्। संयोगेष्वव्याप्यवृत्तिः। श्रोत्रस्थशब्द उद्भूतः। गन्धादयस्त्विन्द्रियवृत्तयोऽनुद्भूताः सर्वद्रव्यवृत्तयः सामान्यगुणा, तदन्ये विशेषगुणाः। ज्ञानेच्छाकृतिसुखदुःखद्वेषसंस्कारशब्दसंयोगेषु . . . . झांकारादेकदेशे उत्पत्तावपि तद्देशत्यागपूर्वकमन्यदेशगतेरानुभाविकत्वादव्याप्यवृत्तित्वम्।

* * * *

Colophon :

इति कृष्णावधूतपण्डितकृतौ काव्यनवनीते पदार्थनिरूपणं नाम प्रथमगोलकम्।

End :

एतल्लक्षणोदाहरणानि मत्कृते चमत्कारचामीकरे स्फुटानि। आसन्तु सर्गकाव्यचम्प्वादि। असत्काव्यं त्याज्यम्। असत्त्वं च कर्तृनेतृप्रयोगहीनत्वेभ्यः। सत्काव्यंग्राह्यम्। सत्त्वं च साधुभिः कर्तृनेतृप्रयोगैः।

काव्यं शुभयशोर्थेभ्यः कान्तावदुपदेशकृत्।
कर्तृनेतृप्रतिष्ठार्थं परानन्दाय मुक्तये॥
काव्यालङ्कारसारस्यसूत्रकारानुसारिणा।
कृतं कृष्णावधूतेन दिङ्मात्रस्य प्रदर्शनम्॥

Colophon :

इति श्रीकृष्णावधूतपण्डितविरचिते काव्यनवनीते फलनिरूपणं नाम पञ्चमं गोलकम्॥

सामाप्तश्चायं ग्रन्थः।

R. No. 5724

Paper. 10¾ × 9¼ inches. Foll. 6. Lines, 20 in a page. Dêvanāgarī. Good. Extent, 125 Granthas. Not printed.

Transcribed in 1935-36 from a MS. obtained on loan from Sri Śarvajñācārya of Hospet.

छन्दोनवनीतम् by कृष्णावधूतपण्डितः

CHANDONAVANĪTAM by Kṛṣṇāvadhūtapaṇḍita.

A treatise on Prosody.

Complete.

Beginning :

मङ्गलाचरणश्लोकं नमामस्सूत्रसंगतम् ।
प्रदर्शयामश्च च्छन्दोरहस्यं नवनीतवत् ॥

छन्दस्त्रिविधम् , वर्णात्मकं मात्रात्मकं वर्णमात्रात्मकंचेति । वर्णच्छन्दः षड्विंशतिः । उक्तात्युक्तामध्या प्रतिष्ठासुप्रतिष्ठागायत्र्युष्णिगनुष्टुब्बृहतीपङ्क्तिस्त्रिष्टुप्जगत्यतिजगतीशक्वर्यतिशक्वर्यष्ट्यत्यष्टिधृतिरतिधृतिः कृतिः प्रकृतिराकृतिविकृतिसङ्कृतिरतिकृतिरुत्कृतिरिति । तत्रैकाक्षरछन्द उक्ता । द्व्यक्षरमत्युक्ता ।

Colophon :

इति श्रीकृष्णावधूतपण्डितविरचितं छन्दोनवनीतम् समाप्तम् ।

End :

यथालगक्रियायां मेरुप्रस्तारः ।

					०		
					१	१	१
				१	२	१	२
			१	३	३	१	३
		१	४	६	४	१	४
	१	५	१०	१०	५	१	५
१	६	१५	२०	१३	६	१	६

R. No. 5725

Paper. 10½ × 9½ inches. Foll. 11. Lines, 20 in a page. Devanāgarī. Good. Extent, 275 Granthas. Not printed.

Transcribed in 1935-36 from a MS. obtained on loan from Śrī Sarvajñācārya of Hospet.

काव्यलक्षणसंग्रहः by कृष्णावधूतपण्डितः

KĀVYALAKṢAṆASAṄGRAHAḤ by Kṛṣṇāvadhūtapaṇḍita.

A treatise on Rhetoric, briefly explaining the characteristics *Kāvyas*, in Sanskrit Literature

Complete.

Beginning :

कृष्णाख्यं ज्योतिरालक्ष्य व्युत्पित्सुसुखबुद्धये ।
कृष्णावधूतो वक्ष्यामि काव्यलक्षणसंग्रहम् ॥
तत्रादौ काव्यसामान्यलक्षणम् -
सालङ्कारगुणौ काव्यशब्दार्थौ दोषवर्जितौ ।
तथा कवीनां समयानुरोधेन निबन्धितम् ॥
शब्दार्थयोरविनाभावात् द्विवचनम् ।

काव्यं विभजते काव्यं ध्वनिः गुणीभूतव्यङ्ग्यं चित्रमितित्रिधा । ध्वनिलक्षणमाह—

वाच्यातिशायिव्यङ्ग्यं यत्तत्काव्यं ध्वनिरिष्यते ।
ध्वन्यन्ते प्राधान्येन व्यज्यन्ते व्यङ्ग्यार्था येनेतिध्वनिः ।

सहृदयानामालोचनसाध्यत्वं प्राधान्यम् । वाच्यार्थादपि व्यङ्ग्यार्थस्य प्राधान्यं यत्र तत्काव्यं ध्वनिरित्यर्थः ।

End :

नगरार्णवशैलर्तु चन्द्रार्कोदयवर्णनैः ।
उद्यानसलिलक्रीडामधुपानरतोत्सवैः ।
विप्रलम्भैर्विवाहैश्च कुमारोदयवर्णनैः ।
मन्त्रद्यूतप्रयाणाद्यैर्नायकाभ्युदयैरपि ।
निबद्धं चेन्महाकाव्यं ससर्गं वाप्यसर्गकम् ।
गीततालानुबद्धं चेत्तन्न्यूनमुपकाव्यकम् ॥
उपकाव्यं कविकल्पिततयाऽनेकविधमूह्यम् ।

Colophon :

इति श्रीकृष्णावधूतपण्डितकृतौ काव्यलक्षणसङ्ग्रहः समाप्तः ॥

R. No. 5726

Paper $10\frac{1}{4} \times 8\frac{1}{4}$ inches. Foll. 15. Lines, 20 in a page. Devanagarī. Good. Extent, 450 Granthas. Not printed.

Transcribed in 1935-36 from a MS. obtained on loan from M.R.Ry. Sarvajñācārya of Hospet.

चमत्कारचामीकरम् अलङ्कारसूत्रभाष्यम् by कृष्णावधूतपण्डितः

CAMATKĀRACĀMIKARAM—ALAṄKĀRASŪTRABHĀṢYAM by Kisṇāvadhūtapaṇḍita.

Foll. 1a—15b.

A commentary on the *Kāvyālaṅkārasūtras*.

Contains the 5th Adyāya only complete.

Beginning :

अथ काव्यं विभजते ।

(सू) ॥ महाकाव्यं प्रायोऽष्टादशवर्णनं सर्गासर्गबन्धम् ॥

नगरार्णवशैलर्तु चन्द्रार्कोदयवर्णनम् ।

उद्यानसलिलक्रीडामधुपानरतोत्सवाः ।

विप्रलम्भो विवाहश्च कुमारोदयवर्णनम् ।

मन्त्रद्यूतप्रयाणानि नायकाभ्युदयास्तथा ।

एषामष्टादशानां यैः कैश्चिन्न्यूनमपीष्यते ।

इत्युक्तेः । प्राय इति सर्गबन्धोऽसर्गबन्धोवा यत्र तन्महाकाव्यम् ।

(सू) ॥ उपकाव्यं गीततालानुबन्धम् ॥

आख्यायिका कथा भोगावलीतारावलीविरुदावली रत्नावलीपञ्चपदाष्टपदीत्याद्युपकाव्यं तालानुबद्धमनेकविधम् ।

End :

(सू) ॥ स्त्रीणां शूरसेनी प्राकृतं मागधी नीचानां देशियाराक्षसानां पैशाची ॥

(सू) ॥ स्वनाम्नः प्रथमपुरुषोऽस्मद इदंशब्दो विनयौद्धत्ययोः ॥

स्वनाम्नः प्रयोगे अस्मदः अस्मच्छब्दस्थाने ।

(सू) लोकपदमब्रह्मण्यादि लोकपदमब्रह्मण्यादि ॥

अब्रह्मण्यमवध्योक्ता वित्यादिलोकप्रयोगानुसारेण बोध्यम् ।

इति भाषानिर्बन्धषट्कः ।

Colophon :

इति श्रीसच्चिदानन्दप्रसादेन श्रीकृष्णावधूतपण्डिताचार्येण विरचित अलङ्कारसूत्रभाष्ये चमत्कारचामीकरे काव्यविभागोनाम पञ्चमोऽध्यायः ।

R. No. 5727

Paper. 10¼ × 9¼ inches. Foll. 63. Lines, 20 in a page. Devanāgarī. Good. Extent, 1,575 Granthas. Not printed.

Transcribed in 1935-36 from a MS. obtained on loan from M.R.Ry. Śarvajñācārya of Hospet.

अद्वैतसूत्रार्थपद्धतिः by कृष्णावधूतः

ADVAITASŪTRĀRTHAPADDHATIḤ by Kiṣṇāvadhūta.

An explanation of the *Brahmasūtras*, according to the *Advaita* school of Ind an Philosophy.

Contains the 1st Adhyāya only complete.

Beginning :

चिदानन्दरूपं गदाब्जपद्मा-
न्युदारं दधानं सदारं सहायम् ।
हृदागम्यमानं सदारं मुनीन्द्रैः
मुदाराधये तन्मदिष्टं महोऽहम् ॥

कृष्णावधूतो वक्ष्यामि जिज्ञासुसुखबुद्धये ।
शारीरकादिसंसिद्धाद्वैतसूत्रार्थपद्धतिम् ॥

वैयासिकी वेदान्तवाक्यनिर्णायिका चतुरध्यायी सूत्र-
सन्दर्भः । तत्राद्वितवस्तुत्तरशतसङ्ख्याकान्यधिकरणानि ।
एकैकस्मिन्नधिकरणे पञ्चावयवाः । विषयः सङ्गतिः
पूर्वपक्षः सिद्धान्त इति । यस्मिन्नधिकरणे यस्यार्थस्य
समर्थनं तत्र सविषयः । संशयो विप्रपत्तिः ।
सङ्गतिर्द्विधा । अन्तर्भावः आनन्तर्यमिति ।

End :

वटधानादिदृष्टान्तस्तु ब्रह्मण्यतीन्द्रियागम्यतया सूक्ष्मत्वादुपपद्यते । असच्छब्दस्य नामरूपराहित्याभिप्रायकत्वं चतुर्थाधिकरणएवोक्तम् स्वभाव-कालपक्षौ पूर्वपक्षत्वेन श्रुतावुपन्यस्तौ । नसिद्धान्ततया । तस्मात् ब्रह्मैव सर्वजगत्कारणं सर्ववेदान्तोक्तमिति ।

Colophon :

इति श्रीमदद्वैताद्वैतविशिष्टाद्वैतवेदान्तप्रक्रियानिष्णातस्य कृष्णाव-धूतस्य कृतौ अद्वैतसूत्रार्थपद्धतौ प्रथमाध्यायस्य चतुर्थः पादः । समाप्तश्च प्रथमोऽध्यायः

R. No. 5728

Paper. 10½ × 9¼ inches. Foll. 23. Lines, 20 in a page. Devanāgarī. Good. Extent, 575 Granthas. Not printed.

Transcribed in 1935–36 from a MS. obtained on loan from M.R.Ry. Sarvajñācārya of Hospet.

वासवदत्ताव्याख्या—पटुबोधपदार्थप्रकाशनम् by कृष्णावधूतः

VĀSAVADATTĀVYAKHYĀ—PAṬUBODHAPADĀRTHAPRAKĀŚANAM by Kṛṣṇāvadhūta.

A commentary on the *Vāsavadattā* of Subandhu. From the colophon, it is known that Kṛṣṇāvadhūta, the commentator, has written, besides this, many other works of which Mandāramakaranda is said to be one. He is said to have lived in Guhapura.

Beginning :

कमलमधुरगात्रं कालकन्दाभगात्रं
कुमुदकमितृगोत्रं क्रूरकंसद्रुदात्रम् ।
खगपरिवृढपत्रं बल्लवीप्रीतिपात्रं
नतजनततिमित्रं नौमि लक्ष्मीकलत्रम् ।
कविर्वासवदत्तीय पटुबोधप्रकाशनम् ।
करोमि कृष्णाशर्माहं बालानां मद्बुद्धये ॥

काव्यं हि यशसेऽर्थाय शिवेतरनिर्वृतये कान्तावदुपदेशाय परनिर्वृतये क्षणादित्युक्त्या विघ्नविघाताभ्यां स्वेष्टवस्तु निर्दिशति । करबदरेति । यस्याः प्रसादतोऽनुग्रहात् कवयः पण्डिताः भुवनतलं लोकभागं करबदरसदृशं पाणिस्थबदरीफलसदृशंयथा तथा । सरस्वती शारदा नदीच प्रसादतो नैर्मल्यात् ।

End :

नरकः दैत्यो नृशिरश्च । रावणश्शब्दकारीच
छुरिकाचासिः योगदृशा ज्ञानदृष्ट्या ।
विधिना दैवेन तत्रैव पाटलीपुत्रनगरे ।
कविर्वासवदत्तीयदुर्बोधपददीपिकाम् ।
परेषामुपकाराय कृष्णशर्मा चकारह ॥

Colophon :

इति श्रीमद्घटिकाशतसरसपद्यकविताचरणनिपुणस्य मन्दारमकरन्दाद्यनेकग्रन्थकर्तुः गुहपुरवासशर्मणः कृष्णावधूतकवेः कृतौ वासवदत्तीयपदुबोधपदार्थप्रकाशनाख्याव्याख्या समाप्ता ॥

R. No. 5729

Paper. 10¼ × 9¼ inches. Foll. 28. Lines, 20 in a page. Devanāgarī. Good. Extent, 700 Granthas. Printed.

Restored in 1935-36 from R. No. 3990.

श्रीभाष्याधिकरणसङ्ग्रहः

ŚRĪBHĀṢYĀDHIKARAṆASAṄGRAHAH.

Complete.

R. No. 5730

Paper. 10¼ × 9¼ inches. Foll. 162. Lines, 20 in a page. Devanāgarī. Good. Extent, 4,050 Granthas. Not printed.

Restored in 1935-36 from D. No. 13113.

कैलासकारकम्

KAILĀSAKĀRAKAM.

Foll. 1a—160b. Foll. 161—162 are left blank.
Incomplete.

R. No. 5731

Paper. 10¼ × 9¼ inches. Foll. 17. Lines, 20 in a page. Devanāgarī. Good. Extent, 425 Granthas. Not printed.

Restored in 1935-36 from D. No. 5378.

श्रियः उपायत्वविचारः

ŚRIYAḤ UPĀYATVAVICĀRAḤ.

Foll. 1a—17a. Foll. 17b is left blank.
Incomplete.

R. No. 5732

Paper. 10¼ × 9¼ inches. Foll. 9. Lines, 20 in a page. Devanāgarī. Good. Extent, 225 Granthas. Not printed.

Restored in 1935-36 from R. No. 4030.

शरभोजिराजप्रशंसा

ŚARABHOJIRĀJAPRAŚAMSĀ.

Wants the beginning and end.

R. No. 5733

Paper. 10½ × 9¼ inches. Foll. 4. Lines, 20 in a page. Devanāgarī. Good. Extent, 60 Granthas. Not printed.

Restored in 1935-36 from R. No. 3990.

प्रयोगरत्नमालिका

PRAYOGARATNAMĀLIKĀ.

Breaks off in the 4th Paṭala.

R. No. 5734

Paper. 10½ × 9¼ inches. Foll. 8. Lines, 20 in a page. Devanāgarī. Good. Extent, 200 Granthas. Not printed.

Restored in 1935-36 from R. No. 4034.

ताललक्षणम्

TĀLALAKṢAṆAM.

Wants beginning and end.

R. No. 5735

Paper. 10½ × 9¼ inches. Foll. 43. Lines, 20 in a page. Devanāgarī. Good. Extent, 1,075 Granthas. Printed.

Restored in 1935-36 from R. No. 623.

खण्डनक्षेत्रमाहात्म्यम्

KHAṆḌANAKṢETRAMĀHĀTMYAM.

Foll. 1a—42b. Foll. 43 is left blank.
Contains Adhyāyas 1 to 14 complete.

R. No. 5736

Paper. 10½ × 9¼ inches. Foll. 36. Lines, 20 in a page. Devanāgarī and Telugu. Good. Extent, 900 Granthas. Printed.

Restored in 1935-36 from D. No. 13208.

रससारसमुच्चयः

RASASĀRASAMUCCAYAḤ.

Foll. 1a—35b. Foll. 36 is left blank.
Complete.

R. No. 5737

Paper. 10¼ × 9½ inches. Foll. 18. Lines, 20 in a page. Devanāgarī. Good, Extent, 450 Granthas. Not printed.

Restored in 1935-36 from D. No. 5491.

वीरशैवदीक्षाविधानम्

VĪRAŚAIVADĪKṢĀVIDHĀNAM.

Foll. 1a—17b. Foll. 18 is left blank.
Complete.

R. No. 5738

Paper. 10¼ × 9½ inches. Foll. 64. Lines, 20 in a page. Devanāgarī. Good. Extent, 1,600 Granthas. Printed.

Restored in 1935-36 from R. No. 3913 (b).

पञ्चाक्षरचक्रविधानम्

PAÑCĀKṢARACAKRAVIDHĀNAM.

Foll. 1a—63a. Foll. 63b—64 are left blank.
Incomplete.

R. No. 5739

Paper. 10¼ × 9½ inches. Foll. 36. Lines, 20 in a page. Devanāgarī. Good. Extent, 900 Granthas. Printed.

Restored in 1935-36 from R. No. 3913 (c).

शल्यादितन्त्रजालम्

ŚALYĀDITANTRAJĀLAM.

Foll. 1a—34b. Foll. 35—36 are left blank.
Incomplete.

R. No. 5740

Paper. 10¼ × 9½ inches. Foll. 44. Lines, 20 in a page. Devanāgarī. Good.

Restored in 1935-36 from D. No. 5087.

(a) पञ्चरत्नव्याख्या—तन्त्रसारप्रकाशिका by वीरणाराध्यः

PAÑCARATNAVYĀKHYĀ—TANTRASĀRAPRAKĀŚIKĀ by Vīraṇārādhya.

Foll. 1a—12a. Extent, 240 Granthas. Not printed.
Complete.

Restored from D. No. 5088.

(b) पञ्चरत्नव्याख्या—तारकदीपिका by रेवणाराध्यः

PAÑCARATNAVYĀKHYĀ—TĀRAKADĪPIKĀ by Revaṇāradhya.

Foll. 13a—18a. Extent, 110 Granthas.

Complete.

Restored from D. No. 5089.

(c) पञ्चरत्नव्याख्या—शिवतत्त्वप्रकाशिका by रेवणाराध्यः

PAÑCARATNAVYĀKHYĀ—ŚIVATATTVAPRAKĀŚIKĀ by Revaṇārādhya.

Foll. 18b—23a. Extent, 100 Granthas.

Complete.

Restored from D. No. 5090.

(d) पञ्चरत्नव्याख्या—श्रुत्यर्थप्रदीपिका—रेवणाराध्यः

PAÑCARATNAVYĀKHYĀ—ŚRUTYARTHADĪPIKĀ by Revaṇāradhya.

Foll. 23b—42a. Foll. 42b is left blank. Extent, 400 Granthas.

Complete.

Restored from D. No. 5107.

(e) शिवज्ञाननतारावली by वीरणाराध्यः

ŚIVAJÑANATĀRĀVALI by Viraṇārādhya.

Foll. 43a—44b. Extent, 25 granthas not printed.

Complete.

R. No. 5741

Paper. 10½ × 9½ inches. Foll. 420. Lines, 20 in a page. Devanāgari. Good. Extent, 10,500 Granthas. Not printed.

Restored in 1935–36 from R. No. 2674.

दैवज्ञविलासः by यल्लयार्यः

DAIVAJÑAVILĀSAH by Yallayārya.

Foll. 1a—420b.

Bound in 3 volumes.

Contains the Ullasas 78 to 103 Complete. 104 and 105 in complete.

R. No. 5742

Paper. 10½ × 9½ inches. Foll. 40. Lines, 20 in a page. Devanāgari. Good.

Restored in 1935–36 from R. No. 3918 (a).

(a) पाणिनिसूत्रविवरणम्

PĀṆINISŪTRAVIVARAṆAM.

Foll. 1a—22b. Extent, 975 Granthas.
Incomplete.
Restored from R. No. 3918 (b)

(b) सूत्रार्थशोधनम्—by भास्कर

SŪTRĀRTHAŚODHANAM by Bhāskara.

Foll. 23a—39. Foll. 40 is left blank. Extent 800 Granthas.
Incomplete.

R. No. 5743

Paper. $10\frac{1}{4} \times 9\frac{1}{2}$ inches. Foll. 18. Lines, 20 in a page. Devanāgari. Good. Extent, 450 Granthas. Not printed.

Restored in 1935–36 from D. No. 5488.

विमलागमः

VIMALĀGAMAḤ.

Foll. 1a—17a. Foll. 17b—18 are left blank.
Incomplete.

R. No. 5744

Paper. $10\frac{1}{4} \times 9\frac{1}{2}$ inches. Foll. 24. Lines, 20 in a page. Devanāgari. Good. Extent, 575 Granthas. Not printed.

Restored in 1935-36 from R. No. 608 (d).

(a) अपूर्वभङ्गः by नारायणमुनिः (श्रीवत्साङ्क)

APŪRVABHAṄGAH by Śrīvatsāṅkasūri.

Foll. 1a—6b. Extent, 150 Granthas.
Complete.
Restored from R. No. 608 (e)

(b) सगुणवादः

SAGUṆAVĀDAH.

Foll. 7a—10b. Extent 100 Granthas. Not printed.
Complete.
Restored from R. No. 608 (f)

(c) भेदवादः

BHĒDAVĀDAḤ.

Foll. 11a—14a. Extent 75 Granthas. Not printed.
Complete.

Restored from R. No. 608 (*g*)

(*d*) प्रपञ्चमिथ्यात्वखण्डनम्

PRAPAÑCAMITHYĀTVAKHAṆḌANAM.

Foll. 14*a*—23*b*. Foll. 24 is left blank. Extent, 250 Granthas. Not printed.

Incomplete.

R. No. 5745

Paper. 10¼ × 9¼ inches. Foll. 34. Lines, 20 in a page. Devanāgarī. Good. Extent, 850 Granthas. Printed.

Restored in 1935–36 from R. No. 4288.

सनत्कुमारसंहिता

SANATKUMĀRASAṀHITĀ.

Foll. 1*a*—34*a*. Foll. 34*b* is left blank.

Wants the beginning of the first paṭala and breaks off in the 5th paṭala.

R. No. 5746

Paper. 10¼ × 9¼ inches. Foll. 8. Lines, 20 in a page. Devanāgarī. Good Extent, 200 Granthas. Printed.

Restored in 1935–36 from R. No. 4030 (*b*).

गङ्गास्तवः

GAṄGĀSTAVAḤ.

Foll. 1*a*—3*b*. Foll. 4 is left blank.

Complete.

R. No. 5747

Paper. 10¼ × 9¼ inches. Foll. 72. Lines, 20 in a page. Devanāgarī. Good. Extent, 1,800 Granthas. Not printed.

Restored in 1935–36 from D. No. 5213.

कपिञ्जलसंहिता

KAPIÑJALASAṀHITĀ.

Foll. 1*a*—72*a*. Foll. 72*b* is left blank.

Contains Adhyāyas 1—9. 22 to 24 complete. 25th incomplete.

R. No. 5748

Paper. 8¼ × 4¼ inches. Foll. 14. Lines, 10 on a page. Devanāgari. Good. Extent, 350 Granthas. Not printed.

Presented in 1935–36 by M.R.Ry. Sarvajñacārya Hospet.

द्वित्ववादार्थः by वेङ्कटेशः

DVITVAVĀDĀRTHAḤ by Veṅkaṭeśa.

A treatise dealing with the nature of 'Dvitva.'

Complete.

अपारभवपाथोधितरणे तरिशेश्वरम् ।
उपास्महे हयग्रीवपदन्द्वन्द्वमहर्निशम् ॥

अत्र द्वित्वं कीदृशमिति नालोचनीयं । एकत्वसमाहाररूपमितिवा व्यासज्यवृत्तिजन्यमिति वा व्यङ्ग्यमिनिवोपपत्तेः । पक्षत्रयमिति सुधारूढं । वैशेषिकाधिकरणसुधायां भेदस्य स्वरूपत्वसमर्थनाय तत्पूर्वपक्षरचनावसरे एकत्वाभावेऽनेकत्वमपि न स्यात् । तत्समाहाररूपत्वात्तत्कार्यत्वाद्वा तस्यांति समाहारत्वोक्तया प्रथनरक्षस्य तत्कार्यत्वोक्तया समुदायस्तु भिन्नग इत्येत-द्व्यारव्यारूपया समुदायोनेकत्वं भिन्नगोऽनेकाश्रितः ।

End :

यत्र स्वाश्रययोरभेदप्रसक्तिरत्रैन भेदाभेदबोधकं समुदायसूते इत्या-दिकमपि एतत्पक्षेऽद्वित्वं स्वपर्याप्त्यधिकरण धर्मिभेदभिन्नमेव नापेक्षा । बुद्धि-भेदप्रयुक्तानन्तभेदवादिति लाघवमवधेयम् । तस्मादयं पक्षो निर्बाधकतमः ; इति संक्षेपः ।

सुधावधीरणे(णा)तोपि दुदूषयिषते परा ।
निवारयति तत्रत्या तत्त्ववाद्यनुबान्धिता ॥
वेङ्कटेशनृसिंहार्यशिष्येण तनयेन वै ।
द्वित्वं व्यचारि सदयं विदांकुर्वन्तु सूरयः ॥

R. No. 5749

Paper. 7 × 4¼ inches. Foll. 70. Lines, 9-12 on a page. Telugu. Injured. Extent, 700 Granthas. Not printed.

Presented in 1935–36 by M.R.Ry. Sarvajñāchārya Avargal, Hospet.

आनन्दरससागरः by आनन्दाश्रमः

ĀNANDARASASĀGARAḤ by Ānandāśrama.

This work teaches that the world is full of misery mingled with happiness and in order to get rid of this worldly existence, one must seek refuge, under a preceptor. The author of the work is Ānandāśrama, disciple of Viśveśvarāśrama.

Complete.

Contains 30 prakaraṇās.

Beginning :

अनन्तगुणकल्याण मनन्तसुखदायकम् ।
अनन्ताख्यं गुरुं सम्यगनन्तं प्रणमाम्यहम् ॥
श्री चिदानन्दाश्रम विरचितानन्दरससागराख्य ग्रन्थ-
स्य निष्प्रत्यूहपरिपूरणायादौ मङ्गलमातनोति ।
उमाधवं माधवञ्च नत्वाभीष्टार्थसिद्धये ।
कुर्वन् निखिललोकस्य तापत्रयनिवारकम् ॥
आनन्दरसविख्यातं सर्वलोकैकसम्मतम् ।
ग्राह्यं वै मन्दबुद्धीनां बुधानाञ्च विशेषतः ॥

इह लोके अधीताखिलवेदशास्त्रसंपन्नो अमानित्वादिसाधनसंयुक्तः कश्चिदाब्रह्मलोकात्सर्वं कर्म कीर्तितमित्यनित्यंमत्वा त्रिभ्यो नितरां विरक्तः सांसारिकसुखाभाससंयुक्तः संसारानलसन्तप्त आध्यात्मिकाधिदैविकाधि-भौतिकरूपसंसारसागरमध्यजनितगतायाततरङ्गसंयोगवियोगरागद्वेषादि नक्रग्रह-समेतपुत्रमित्रकलत्रादिविमोहावर्ताज्ञानशैवालाल्पसुखासक्त वैसारीणागाध-विषयजलागाधापारनिमज्जनोन्मज्जनजननमरणवीचिकल्लोलादिकमहाघोष रोदना-तिशान्तनिरन्तरङ्गहर्षसमेतसुखदुःखात्मकसंसारसागर मुत्तितीर्षुः सद्गुरुं प्राप्य उपहारपाणिः प्रसन्नः सद्गुरून् प्रति पृच्छति ।

Colophon :

इति शिष्याधिकरणं नाम प्रथमप्रकरणम् ।

End :

अत्र भिदा(दा)मिव मन्यमानः शतधा सहस्रधा अनेकधा भिन्नो भवति । ब्रह्मणोपि देवान्प्रतिवेदार्थपरमद्विद्वं अनिश्रितार्थश्रेन्मूर्धा युष्माकं च पतिष्यति । "इतः परं न वक्तव्यं विद्यते सुरपुङ्गवाः । सत्यमेव मया प्रोक्तं शंभोः पादौ स्पृशाम्यहम् " ॥

Colophon :

इति सूतसंहितायां ब्रह्मणो देवानाञ्च संवादः । एतदानन्दरससागराख्यग्रन्थाध्ययनान्मुक्तः सर्वोत्कृष्ट इति सिद्धं । नविचिकित्सास्पदम् । आनन्दाश्रमस्वामिभिः विश्वेश्वराश्रमाशिष्येभ्यः कृतमानन्दरससागरम् ।

Colophon :

इति श्रीमत्सदानन्दचिदघनानन्दाश्रम वरशिष्यपरमहंसपरिव्राजकाचार्य आनन्दाश्रमविरचितसंस्कृतभाषारूपानन्दरससागराख्यग्रन्थे सार्वोपनिषदर्थप्रतिपादकयोगो नाम त्रिंशत् प्रकरणं संपूर्णम् ।

Scribe adds

दुन्दुभिसंवत्सरं

R. No. 5750

Paper. 9¼ × 4 inches. Foll. 18. Lines, 11 on a page. Devanāgarī. Good. Extent, 220 Granthas. Not printed.

Presented in 1935-36 by Śrī Sarvajñācharya Avargal, Hospet.

अद्वैतनवनीतम् by कृष्णावधूतपण्डितः

ADVAITANAVANĪTAM by Kṛṣṇāvadhūtapaṇḍita.

This work gives in brief the essence of Advaita.

Complete.

Beginning :

वयं वन्दामहे भूयः कर्म किं तदकर्मकम् ।
नयप्रयोगतो भावे प्रयोगः कर्तृकर्मणोः ॥
अद्वैतं मतमवलोक्य कोणकोणं
निश्शेषं नवनवनीत उद्धरिष्ये ।
धीमन्तोऽनिलसमये विहर्तुमन्तः
काङ्क्षन्तः सपदि सुखं गिलन्तु सन्तः ॥
प्रक्रिया च प्रमेयञ्च प्रमाणं दोष उच्यते ।
क्वचि दुक्तानुवादोपि संगत्या मतभेदतः ॥

पादोऽस्य विश्वाभूतानि त्रिपादस्यामृतं दिवीतिश्रुतिः। ब्रह्मणो मूलप्रकृत्यधिष्ठानभूतः पाद एकः। पादत्रयंतु अमृतरूपं दीप्यमान शुद्धनिर्धर्मिकं अनादेर्मूलप्रकृतेः प्रधानं अव्यक्तमितिनाम। माया अविद्यातामसी, राजसी, सात्विकेत्येतत्समष्टिरूपा। अनादयोऽनन्तजीवाः स्वस्वकर्मवासनादिभिः सहजतुपिण्डे सुवर्णरेणव इव प्रकृतौलीनाः सन्ति।

Colophon :

इति श्रीकृष्णावधूतपण्डितकृतौ अद्वैतनवनीते प्रक्रियानिरूपणं नाम प्रथमगोलकम्।

End :

ऐश्वर्यस्याविद्यकत्वात्। नहीश्वरस्याविद्या। निरञ्जनत्वात्। बद्धपुरुषान्तराविद्याकल्पितमेव। तस्मान्मुक्तस्यैश्वरभावोयुक्तः।

निन्दको निकटेमेस्तु दोषमादाय तोषकृत्।
गृहिणः श्रीमतो यद्वद्विष्टागतौ गृहान्तिके॥
यस्योपास्योपदेष्टारौ सूत्रकृत्समवर्तिनौ।
जाप्यौ च तारकाष्टार्णौ तेनेदंकृतमर्थिसात्॥

Colophon :

इति श्रीकृष्णावधूतपण्डितविरचितेऽद्वैतनवनीते मतभेदानिरूपणं नाम पञ्चमगोलकम्। समाप्तश्चायं ग्रन्थः।

R. No. 5751

Paper. 9½ × 4 inches. Foll. 14. Lines, 9–11 on a page. Devanāgarī. Good. Extent, 130 Granthas. Not printed.

Presented in 1935–36 by M.R.Ry. Sarvajñācharya Avargal, Hospet.

तर्कनवनीतम् by कृष्णावधूतपण्डितः

TARKANAVANĪTAM by Kṛṣṇāvadhūtapaṇḍita.

In this work, the author gives the essential points of the Nyāya system.

Incomplete.

Beginning :

गोपवधूटीदयितं नत्वा निर्मथ्य तर्कदधिराशिम् ।
तत्सारं नवनीतं समुद्धरामः सुखाय बालेभ्यः ॥

पदार्थोद्विविधः । भावाभावाविति । भावः षड्विधः । द्रव्यगुणकर्म सामान्यविशेषसमवायभेदात् । द्रव्याणि नव पृथिवीजलतेजोवायुव्योमकाल दिगात्ममनांसीति । पृथिवीजलतेजोवायूनां परमाणवः आकाशकालदिगात्ममनांसिचनित्यद्रव्याणि । उत्पत्तिनाशरहितत्वं नित्यत्वं । पृथिवीजलतेजोवायूनां शरीरेन्द्रियविषयाः अनित्याः । उत्पत्तिविनाशवदनित्यं । पृथिवीशरीरं चतुर्विधम् । जरायुजमण्डजं स्वेदजमुद्भिज्जमिति ।

End :

युक्ताङ्गराहित्यं, अयुक्ताङ्गाधिक्यं, अनुचितविषय वृत्तित्वचेति त्रिविधमसामर्थ्यमसाधारणम् । एतत्सर्वं मत्कृते लोकोपकारे मुद्रिते द्रष्टव्यम् । निग्रहस्थानानितु प्रतिज्ञाहानिः, प्रतिज्ञान्तरं, प्रतिज्ञाविरोधः, प्रतिज्ञासन्यासो, हेत्वन्तर, मर्थान्तरं निरर्थकमविज्ञातार्थकमपार्थकम प्राप्तकालं न्यूनमधिकं पुनरुक्त मननुभाषण मज्ञानमप्रतिभाविक्षेपो मतानुज्ञापर्यनुयोज्यो . . . . .

R. No. 5752

Paper. 11¼ × 6¼ inches. Foll. 19. Lines, 12 on a page. Devanāgarī. Slightly injured. Extent, 405 Granthas. Printed.

Presented in 1935-36 by Śrī Sarvajñācārya Avḷ., Hospet.

पराशरधर्मशास्त्रम् by पराशरः

PARĀŚARADHARMAŚĀSTRAM by Parāśaraḥ.

Same work as that described under D. No. 5275.

1 to 10 Adhyāyās complete.

R. No. 5753

Paper. 12½ × 5¼ inches. Foll. 43. Lines, 12 on a page. Devanāgarī. Good. Extent, 1,680 Granthas. Not printed.

Presented in 1935-36 by M.R.Ry. Sarvajñacarya, Hospet.

वेदान्तरत्नमाला—अलङ्कारादर्शसहिता by श्रीनिवासः ।

VEDĀNTARATNAMĀLĀ with ALAṄKĀRĀDARŚA by Śrīnivāsa.

Same work as that described under R. No. 3831.

R. No. 5754

Paper. 11½ × 6 inches. Foll. 6. Lines, 10 on a page. Devanāgarī. Injured. Extent, 50 Granthas. Printed.

Presented in 1935-36 by M.R.Ry. Sarvajñācārya Avl, Hospet.

विशिष्टाद्वैतविजयवादः by नरहरिः
VIŚIṢṬĀDVAITAVIJAYAVĀDAḤ by Narahari.

In this work, the author reputes the objections raised by other schools of thought against the Viśiṣṭādvita school and establishes that only the views of the Viśiṣṭādvaita school satisfy the sense expressed by the Upaniṣads.

Complete.

Beginning :

पायात्सर्वः (वः) स्वव्यतिरिक्तसर्व

वपुश्श्रयोऽन्तर्धिषणोत्तमः पुमान् ।

यस्याः कटाक्षयत(क्षायत) भाष्यदृष्ट्या

सुनिर्गुणो मऽयगुणाकरोऽभूत् ॥

अत्र खलु अखिलहेयप्रत्यनीककल्याणगुणगणैकतानं स्वेतर समस्तवस्तु विलक्षणं विशिष्टाद्वैतं ब्रह्म सर्व श्रुतिस्मृतीतिहास पुराण वेद्य मिति श्रीमद्रामानुजाचार्यैः भाष्ये राद्धान्तितम् ॥

End :

कूर्मरोमादि विभ्रम इत्यादिकं तु भाष्यादावेव सुस्पष्ट मित्युक्तमिति विस्तरभयान्नेह लिख्यते ।

यतीश्वरसरस्वती सुरभिताशयानांमुदे

प्रसङ्गरणमण्डले विजयनाथमेतन्मया ।

कृतं सुकृतिनां सतां स्वगणपाशनावलं

सु . . त्यविजयं शुभंग . . वते प्रयच्छन्तु वै ॥

Colophon :

इति श्रीनैध्रुवकाश्यपगोत्रपवित्रेण श्रीमद्राघवसूनु(श्रीनि)वासकुल विद्वच्चूडामणिना नरहरिनाम्ना विरचिते विशिष्टाद्वैत विजयवादः समाप्तः ।

R. No. 5755

Paper. 11¾ × 4 inches. Foll. 23. Lines, 10 on a page. Devanāgarī. Injured
Extent, 715 Granthas. Not printed.

Presented in 1935-36 by M.R.Ry. Sarvajñācārya Avl, Hospet.

पार्वतीकल्याणम् by हरियज्वा

PĀRVATĪKALYĀṆAM by Hariyajvan.

A drama in seven acts describing the marriage of Pārvatī with Śiva. Complete.

Beginning :

आम्नायैर्य ऋगादिभिः स्मृतिगणै स्तन्त्रैविहातागमै-
रङ्गैः षड्भिरभिष्टुतः सुरवरैः ब्रह्मादिभिर्वन्दितः ।
भूम्यंभोऽनलवायु रवार्कशशभृद्यज्वाष्टमूर्तिःसवः
कल्याणानि निरन्तरं वितनुताच्छैलेन्द्रजावल्लभः ॥
ईशानः सर्व विद्यानां सर्वभूतश्चरेश्वरः ।
ब्रह्मविष्ण्वादिदेवेड्यः पातु वोऽनारतं शिवः ॥
(नान्द्यते सूत्रधारः प्रविश्येतस्ततः परिक्रम्य)

End :

महोभिरष्टभिश्चैतं नाटकं हरियज्वना ।
कृत्वाष्टमूर्त्तये भक्त्या शङ्कराय समर्पितम् ॥
ये पठिष्यन्ति सतत मेतं नाटकमुत्तमम् ।
ते पूर्णार्था भविष्यन्ति पुरुषाः लोकयोर्द्वयोः ॥
यदिरु कारीति हि सध्रीचीना न विद्यते ।
तथार्पीयं कथापूज्या पापघ्नी परमेश्वरी ॥

Colophon :

इति नरहरिसूरिसूनुना हरियज्वना प्रणीते पार्वतीकल्याणाभिधे नाटके सप्तमोऽङ्कः समाप्तः ।

R. No. 5756

Paper. 12 × 4¾ inches. Foll. 18. Lines, 11 on a page. Devanāgarī. Much injured. Extent, 433 Granthas. Not printed.

Presented in 1935-36 by M.R.Ry. Sarvajñācārya Avl., Hospet.

रुक्मिणीकल्याण चरितम् by श्यामाचार्यः ।

RUKMIṆĪKALYĀṆACARITAM by Syāmācārya.

This is a poem describing the marriage of Rukmini with Krsna. Complete.

Beginning :

सेवे सारसनयनं भावे वसुदेवदेवकी सूनुम् ।
नन्दयशोदानन्दं वन्दे वन्दारु म . . . . . ॥
कलये हृदये कमलां करुणालोकाश्रितार्तिहतविमलाम्
अधिगतमणिमयमालां विष्णुसतीं नौमि शुभलीलां ॥
भुवनतलेऽधिकमहितापूरासीद्द्वारकेति नामयुता ।
समुदितसद्गुणविहिता द्यौरिव लोकेषु विख्याता ॥

End :

एवं कृत्वा शौरिः संभृतकामः सुरुक्मिणीदेव्याः ।
. . . . . . क्ष्मीदेव्या यथा विष्णुः ॥
इति चरितं रुक्मिण्याः शृण्वन्ति पठन्ति वाचय . . . ।
. . . . . . त्र प्रथितयशस्विनो महानन्दाः स्युः ॥

Colophon :

इति श्रीमद्वाधूलवंशामृतनिधि . . . . . तज्ज्येष्ठेनानन्तपादद्वय विहितधिया श्यामनाम्ना कृतेयम् ।

R. No. 5757

Paper. 8¼ × 4½ inches. Foll. 7. Lines, 10 on a page. Devanāgarī. Much injured. Extent, 121 Granthas. Not printed.

Presented in 1935-36 from M.R.Ry. Sarvajñācārya Avl, Hospet.

सुभाषितरत्नमञ्जरी by नरसिंहाचार्यः

SUBHĀṢITARATNAMAÑJARĪ by Narasiṁhācārya.

This is a work on anthology.
Complete.

Beginning :

वन्दे वन्दारुवृन्दाना ममन्दानन्ददायि यत् ।
तदिन्दि(इन्दि)रामन्दिरोरस्कं दरं सुन्दरं महः ॥

कवीन्द्रमण्डलीक्लृप्तसुविचित्रपदक्रमा ।
विभाति भुवनश्लाघ्या सरसीव सरस्वती ॥

शारदोल्लासविभ्राजदवदातगुणोदया ।
हंसीव कविता भाति सारसोदारविभ्रमैः ॥

End :

यस्त्रभूतनयोल्लासी सद्यशो . . . चितः ।
ससुमित्रात्मजो भास्वत्सन्तानप्रथयैधत ॥

घनगिरिकुलसिन्धुशीतभानोः
कृतिरिह वेङ्कटनारसिंहनाम्नाम् ।

मृदलतरमुदां मुदे बुधानां
भवतु सुभाषितरत्नमञ्जरीयम् ॥

Scribe adds.

अङ्गीरसाब्दे आषाढे सप्तम्यां शुक्लपक्षके ।
लिखितं श्रीनिवासेन बालसंघस्य तुष्टये ॥

Colophon :

इति श्रीमत्कविकुलशिरोमणिनरसिंहाचार्यकृतसुभाषितरत्नमञ्जरी समाप्ता ।

R. No. 5758

Paper. 11¼ × 4¼ inches. Foll. 28. Lines, 10 on a page. Devanāgarī. Much injured. Extent, 756 Granthas. Printed.

Presented in 1935-36 by M.R.Ry. Sarvajñācārya Avargal, Hospet.

यमकभारतम् by आनन्दतीर्थः टीका by यदुपत्याचार्यः

YAMAKABHĀRATAM by Ānandatīrtha, Ṭīkā by Yadupatyācārya.

Same work as that described under D. Nos. 11888 and 11890.

Complete.

R. No. 5759

Paper. 7 × 4½ inches. Foll. 17. Lines, 7–9 on a page. Telugu. Good. Extent, 200 Granthas.

Presented in 1936–37 by M.R.Ry. Sarvajñācārya, Hospet, Bellary district.

वेदान्तकारिकावली by बुच्चि वेङ्कटाचार्य

VEDĀNTAKĀRIKĀVALĪ by Bucchi Veṅkaṭācārya.

Same work as that described under D. No. 5005.

R. No. 5760

Palm leaf. 16 × 1¼ inches. Foll. 59. Lines, 12 on a page. Grantha. Slightly injured. Extent, 2,832 Granthas. Printed.

Presented in 1935–36 by M.R.Ry. K. C. Gopala Ayyangar Avargal. Sub-Judge, Vizagapatam.

सङ्कल्पसूर्योदयः by वेदान्तदेशिकः

SAṄKALPASURYŌDAYAH by Vēdāntadēśika.

Same work as that described under D. No. 12710.

Complete.

R. No. 5761

Palm leaf. 16 × 1¼ inches. Foll. 60. Lines, 10 on a page. Grantha. Much injured. Extent, 2,00) Granthas. Printed.

Presented in 1935–36 by M.R.Ry. K. C. Gopalan, B.A., B.L., Sub-Judge, Vizagapatam.

सङ्कल्पसूर्योदयव्याख्या

SAṄKALPASŪRYODAYAVYĀKHYĀ.

Same work as that described under D. No. 12715. Wants beginning and end.

R. No. 5762

Palm leaf. 15 × 1¼ inches. Foll. 75. Lines, 13 on a page. Grantha. Slightly injured. Extent, 3,700 Granthas. Printed.

Presented in 1935–36 by M.R.Ry. K. C. Gopalan, B.A., B.L., Sub-Judge, Vizagapatam.

रामायणम्

RĀMĀYAṆAM.

Same work as that described under D. No. 1807.

Contains Sundarakāṇḍa. Complete.

R. No. 5763

Palm leaf. 15 × 1¼ inches. Foll. 154. Lines, 10 on a page. Grantha. Slightly injured. Extent, 6,000 Granthas.

Presented in 1935-36 by M.R.Ry. K. C. Gopalan, B.A., B.L., Sub-Judge, Vizagapatam.

रामायणम्

RĀMĀYAṆAM.

Same work as that described under D. No. 1853.

Sundarakāṇḍa only complete.

R. No. 5764

Palm leaf. 16 × 1¼ inches. Foll. 150. Lines, 8 on a page. Grantha. Slightly injured. Extent, 4,800 Granthas. Printed.

Presented in 1935-36 by M.R.Ry. K. C. Gopalan, B.A., B.L., Sub-Judge, Vizagapatam.

रामायणम्

RĀMĀYAṆAM.

Same work as that described under No. 1807.

Contains 1—4 kāṇḍas complete.

R. No. 5765

alm leaf. 14 × 1¼ inches. Foll. 200. Lines, 8 in a page. Grantha. Slightly injured. Extent, 4,800 Granthas. Printed.

Presented in 1935-36 by M.R.Ry. K. C. Gopalan, B.A., B.L., Sub-Judge, Vizagapatam.

सेतुमाहात्म्यम्

SETUMĀHĀTMYAM.

Same work as that described under D. No. 25°9.

Complete.

R. No. 5766

Palm leaf. 15 × 1¼ inches. Foll. 138. Lines, 8 in a page. Grantha. Slightly injured.

Presented in 1935-36 by M.R.Ry. K. C. Gopalan, B.A., B.L., Sub-Judge, Vizagapatam.

(a) प्रपत्तिविषयः

PRAPATTIVIṢAYAḤ.

Foll. 1a—5b. Extent, 150 Granthas. Not printed.
Same work as that described under R. No. 660 (f).
Incomplete.

(b) ब्रह्मसूत्रम्

BRAHMASŪTRAM.

Foll. 6a—16b. Extent, 330 Granthas. Printed.
Same work as that described under R. No. 299.
Complete.

(c) वेदान्तदीपः by रामानुजाचार्यः

VEDĀNTADĪPAḤ by Rāmānujācārya.

Foll. 17a—138b. Extent, 3,400 Granthas. Printed.
Same work as that described under D. No. 5013.
Complete.

R. No. 5767

Palm leaf. 14 × 1¼ inches. Foll. 83. Lines, 7 in a page. Grantha. Slightly injured. Extent, 1,660 Granthas. Printed.

Presented in 1935-36 from M.R.Ry. K. C. Gopalan, B.A., B.L., Sub-Judge, Vizagapatam.

भागवतम्—सव्याख्यानम्

BHĀGAVATAM—with commentary.

Same work as that described under D. No. 2180.
Contains the 6th skandha only.

R. No. 5768

Palm leaf. 13 × 1¼ inches. Foll. 50. Lines, 8 in a page. Grantha. Slightly injured. Extent, 1,000 Granthas. Printed.

Presented in 1935-36 by M.R.Ry. K. C. Gopalan, B.A., B.L., Sub-Judge, Vizagapatam.

कृष्णयजुर्वेदकाठकम्

KṚṢNAYAJURVEDAKĀṬHAKAM.

Same work as that described under D. No. 184.

Complete.

Foll. 46—50 contains Ācāryatanians.

R. No. 5769

Palm leaf. 12 × 1¼ inches. Foll. 67. Lines, 8 in a page. Grantha. Injured Extent, 1,800 Granthas.

Presented in 1935-36 by Śrī K. C. Gopalan, B.A., B.L., Sub-Judge, Vizagapatam.

श्रीगुणरत्नकोशः सव्याख्यः by पराशरभट्ट and श्रीनिवास.

ŚRĪGUṆARATNAKOŚAḤ with Commentary by Parāśarabhaṭṭa and Śrīnivāsa.

Incomplete.

Similar to the work described under D. No. 9756.

Beginning :

श्रीपराशरभट्टार्यः श्रीरङ्गेशपुरोहितः ।
श्रीवत्साङ्कसुतः श्रीमान् श्रेयसेमेऽस्तुभूयसे ।
श्रीलक्ष्मणार्यकरुणापरिलब्धबोधः
श्रीमन्महाजनकदेशिकशिक्षितार्थः
श्रीश्रीनिवास इह कौशिकवंशजन्मा
व्याख्याति विष्णुरमणीगुणरत्नकोशम् ॥

इह खलु हारीतकुलतिलकश्रीवत्साङ्कमिश्रनन्दनः श्रीरङ्गनाथतन्नायिकाभ्यां यथाविधि सकललोकसाक्षिकं नवीकृतपूर्वसंबन्धः स्वजननीभूत-श्रीरङ्गनायिकानिर्हेतुकपरमकृपयावाप्तसमस्तशास्त्रः निस्संशयमधिगतसमस्ततत्वरहस्यार्थविशेषः श्रीभाष्यकारकृपापरिपूर्णविजृम्भितसकलाभ्युदयशाली श्रीरङ्गेशपुरोहितः श्रीभट्टार्यः . . . .

सतत मनुसन्धातव्य श्रीगुणरत्नकोशाख्यं श्रीरङ्गनायिकास्तोत्रं चकार ।

End:

किंच विश्लिष्य वासो वने विश्लिष्य क्षणविश्लेषासहं स्वेनापि क्षणं विसोढुमशक्यं भगवन्तं रामात्मनावतीर्णं वियुज्य विरहय्येत्यर्थः। वने रावणभवनोपवने वासोजातः।

R. No. 5770

Palm leaf. 16 × 1¼ inches. Foll. 122. Lines, 10 in a page. Grantha. Slightly injured. Extent, 3,904 Granthas. Printed.

Presented in 1935-36 by Śrī K. C. Gopalan, B.A., B.L., Sub-Judge, Vizagapatam.

भागवतव्याख्या—अन्वयः by वेङ्कटकृष्णः

BHĀGAVATAVYĀKHYĀ—ANVAYA by Veṅkaṭakṛṣṇa.

Same work as that described under D. No. 2238.

Contains 5th skandha complete.

R. No. 5771

Palm leaf. 15 × 1¼ inches. Foll. 79. Lines, 7 in a page. Grantha. Slightly injured. Extent, 2,196 Granthas. Printed.

Presented in 1935-36 by Śrī K. C. Gopalan, B.A., B.L., Sub-Judge, Vizagapatam.

भागवतम्

BHĀGAVATAM.

Same work as that described under D. No. 2162.

Contains 10th skandha incomplete.

R. No. 5772

Palm leaf. 16 × 1¼ inches. Foll. 78. Lines, 14 in a page. Grantha. Slightly injured. Extent, 3,900 Granthas. Printed.

Presented in 1935-36 by Śrī K. C. Gopalan, B.A., B.L., Sub-Judge Vizagapatam.

भागवतव्याख्या—तात्पर्यचन्द्रिका by वेङ्कटकृष्ण

BHĀGAVATAVYĀKHYĀ—TATPARYACANDRIKĀ by Veṅkaṭakṛṣṇa.

Same work as that described under D. No. 2238.

Contains 11th skandha only.

R. No. 5773

Palm leaf. 15 × 1¼ inches. Foll. 82. Lines, 12 in a page. Grantha. Slightly injured. Extent, 3,280 Granthas. Not printed.

Presented in 1935–36 by Śrī K. C. Gopalan, B.A., B.L., Sub-Judge, Vizagapatam.

भागवतम् - अन्वयव्याख्यासहितम् by वेङ्कटकृष्णः

BHAGAVATAM with ANVAYAVYĀKHYA by Venkatakṛṣṇa.

Same work as that described under D. No. 2238.

Contains 12th skandha only.

R. No. 5774

Palm leaf. 14 × 1¼ inches. Foll. 75. Lines, 5 on a page. Grantha. Much injured. Extent, 1,350 Granthas. Printed.

Presented in 1935–36 by Śrī K. C. Gopalan, B.A., B.L., Sub-Judge, Vizagapatam.

स्तोत्ररत्नम् by यामुनाचार्यः

STOTRARATNAM by Yāmunācārya.

Same work as that described under R. Nos. 160 (*t*) and 173 (*g*).

Complete.

R. No. 5775

Paper. 10¼ × 9¼ inches. Foll. 44. Lines, 20 in a page. Dēvanāgarī. Good. Extent, 1,100 Granthas. Not printed.

Transcribed in 1936–37 from a MS. of Śrī Sarvajñācāryar of Hospet.

इन्दिराभ्युदयचम्पूः by रघुनाथकविः

ĪNDIRĀBHYUDAYACAMPŪḤ by Raghunāthakavi.

Foll. 1*a*—44*b*.

A work, in the *Campu* style, on the Puranic story of Goddess Mahālakṣmī, the Consort of God Viṣṇu.

Complete.

Beginning :

वन्दे तं देवमनिशं वाञ्छितार्थप्रदं सदा (सताम्)।
यो हरिस्सकलैः कण्ठादुपर्यवति कथ्यते ॥

संसाराब्धिं विमथ्य स्वमतिभुजगराड्बद्धशास्त्राद्रिणा तत्
सन्तापदवेलमुग्रं भवगतमखिलं साधुबुध्वाबुधौघः ।
अक्षीणां भक्तिलक्ष्मीमपि सहजविवेकेन्दुमानन्दयोगा
द्यस्मिन्निक्षिप्य यस्मात्स्वयममृतमगात्तत्पदाब्जं भजेऽहम् ॥

* * * *

विष्णुपदसेवको यस्सत्वामृतकरोद्विजाधिराजश्च ।
सकथं विषादभाक्स्यात्तदपि कदाचित्पुनर्हरिं भजते ॥

तत्तादृशोऽहमवकर्ण्य हरिर्विषार्मे
भीतः पपौ हरइति प्रविशङ्कितचेताः ।
निद्रामवापमथ कश्चिदुवाचविप्रः
स्वप्ने किमेवमिति भागवतानभिज्ञः ॥

अथ भागवतं श्रुत्वा व्यक्ततत्त्वसुधां कथाम् ।
सन्तोषमगमं तत्र निगमंभूरि चिन्तयन् ॥

ततस्तथाश्चार्यं करबदरयन्बालकतते
रपिप्रीत्यै पद्मा कमन(ल)पदसेवारतिजुषाम् ।
इदंश्रव्यंकाव्यं गुणिभिरिह पद्माम्युदयमि
त्युदारंकुर्वेहं ननसुलभनारा(यण) परम् ॥

End :

यद्यद्धरियारम्यप्रकटनमस्तीहतत्तदखिलमपि ।
श्री भागवते पाद्मे स्कान्देऽन्यत्रापिसूत्रमेवबहु ॥
रसमधुकलितैस्सद्गुणपरिमलभरितैस्सचित्रकिञ्जल्कैः ।
हरिरर्चितो वचोमयैः कुसुमैरतैःश्रियं तनोतु मम ॥
ऋतुनिधिदिङ्निगमाख्या प्रकटितसङ्ख्याक कलियुगाब्दानाम् ।
उपरिरचितः प्रबन्धो जयतुचिरं विष्णुवल्लभाम्युदयः ॥

Colophon :

इति श्रीवत्सकुलज श्री रघुनाथकविवरविरचिते श्रीमदिन्दिराभ्युदयाह्वये चम्पूप्रबन्धे अभ्युदयोल्लास स्तुरीयाधिक(ार):

R. No. 5776

Paper. 10½ × 9¼ inches. Foll. 68. Lines, 20 in a page. Devanāgarī. Good. Extent, 1,700 Granthas. Not printed.

Transcribed in 1936–37 from a MS. obtained on loan through Dr. T. R. Cintāmaṇi, M.A., PH.D., Senior Lecturer in Sanskrit, Oriental Research Institute, University of Madras.

न्यायसारव्याख्या—न्यायकलानिधिः by आनन्दानुभवः

NYĀYASĀRAVYĀKHYĀ—NYĀYAKALĀNIDHIḤ by Añandānubhava.

Foll. 1*a*—65*a*. Foll. 65*b*, 66, 67 and 68 are left blank.

This is a commentary on the Nyāyasāra of Bhāsarvajña.

Complete.

Beginning :

दिनकरकरचयशशिकरसङ्घा
नुपहतमपि घनघननिबिडंयत् ।
नतजनहृदयकुहरगतमान्द्यं
प्रहरति तदवतु पदमिह वाण्या (:) ॥

रतिपतिखरतरशरचयभिन्नाः
किमुदिवि कतिकतिनहि सुरसंघाः ।
जयति (स) पशुपतिरिहगिरिकन्या
समवपुरपि रति (पति) जयकृद्यः ॥

गणपतिपदयुग्मं किं ननमति जडधीर्लोकः ।
यदखिलदुरितौघघ्नं सकलफलजनेर्हेतुः ॥

महादेवाश्रमंवन्दे गुरुं चिन्तामणिनवम् ।
अनित्यफलदं नानाविद्याधरशिरोमणिम् ॥

न्यायसारकुमुदोदराहृत न्यायतन्त्रमधुदानकौतुकी ।
श्रोतृभृङ्गसुखदो विरच्यते युक्तिरश्मिरुचिरः कलानिधिः ॥

शिष्टाचारपरिपालनायाविघ्नसमाप्तिप्रचयगमनयथाशास्त्रार्थस्फुरणसि- द्ध्यर्थं विशिष्टेष्टदेवतानमस्कारपूर्वकं ग्रन्थप्रतिपाद्यमर्थमाद्यश्लोकेन सुखबो- धायदर्शयति—प्रणम्येति ।

Colophon :

इत्यानन्दानुभवाचार्यकृते न्यायकलानिधौ अनुमानपरिच्छेदस्समाप्तः ।

End :

न्यायरत्नमाचार्यमाराध्य मयापिलब्धं स्वरोपकारिभूतं, ननुकथं परेषां तेनोपकाराद्यदत्यत आह—उत्सर्जितमिति । द्विजानां संसारमुक्त्यै ग्रन्थ- गौरवभीत्या स्वपादौर्निबध्योत्सर्जितमित्यर्थः ।

Colophon :

इत्यागमपरिच्छेदेन्यायसारटिप्पणे आनन्दानुभवाचार्यकृतेन्यायकला निधौ श्रीमन्महादेवाश्रमशिष्येण यागिना विश्वनाथाश्रमेणार्य कृतेन्यायक- लानिधिस्समाप्तः

R. No. 5777

Paper. 10½ × 9¼ inches. Foll. 206. Lines, 20 in a page. Devanāgarī. Good. Extent, 6,135 Granthas.

Transcribed in 1936-37 from a MS. of Śrī Narasimhācāryar Avargal, Oriental Library, Mysore.

श्रीभाष्यभावप्रबोधनम् by मेघनादारिः

SRĪBHĀṢYABHĀVAPRABODHANAM by Meghanādāri.

Foll. 1*a*—205*a*. Foll. 205*b* and 206 are left blank.

In this work, the author Meghanādāri throws light on the views of the Viśiṣṭādvaita school contained in the Śrībhāṣya of Śrī Rāmānuja. The author refers to his work Nayaprakāśika, the commentary on the Śrībhāṣya which work has been described under D. No. 4958.

Contains the first pāda of the first adhyāya.

Beginning :

वागादिभिर्गुरून् भाष्य नाथार्यादीन् कृपालयान् ।
रामानुजं यतिवरं तत्पूर्वानपि देशिकान् ॥
लक्ष्मी वक्षसि बिभ्राणं हयास्यं च तमोपहम् ।
यते वेदान्तभाष्येषु गुरुभावप्रबोधने ।

नयप्रकाशिके प्रायो न्यायमार्गाः प्रदर्शिताः ।
भाष्याणान्त्वतिगम्भीरः क्रमाद्भावो न बोधितः ।
अबोधितस्स न ज्ञातुं शक्यो विद्वत्तमैरपि ॥
द्वित्रिश्रवणमात्रेण गुरुसेवालसात्मभिः ।
अबोधोवा श्रुतांशानामपि सेवारतात्मनाम् ।
सत्संप्रदायविच्छेदात्तदुत्सादो भवेत्ततः ।
निराबाधात्त्रयीमार्गात् भ्रष्टा निरयगामिनः ।
अतः प्रयत्नो नानर्थो भाष्यभावप्रबोधने ।
श्रुते यद्यपि कार्त्स्न्येन स्मृतोनेति नहीयते ॥

* * * *

ब्रह्मसूत्रव्याख्यारंभे स्वाभिलषित भगवद्भक्तिप्रार्थनं न सङ्गतम् । सेतुं प्रति जिगमिषोर्हिमवद्गमनमिवेतिचेन्न । प्रारिप्सितस्याविघ्नपरिसमाप्तिप्रचय-गमनयोः सिध्यर्थं पूर्वाचरितमङ्गलाचारपरत्वात् महाभाष्यकारादिभिः न तदाचारः कृत इति भाष्यारम्भे न तद्युक्तमिति चेत् तन्न, अथशब्दानु-शासनमित्यादौ अथादिशब्देनप्रयोगैस्तेषामपि तदाचारात् स्वाभिलषितभक्ति-प्रार्थनं न मङ्गलाचार इति चेत् तन्न । वृषोभिलषित इत्यादौ धर्मादिदर्शना-देरपि इष्टसाधनत्वस्मरणात् ।

End :

किन्त्वेवंविधस्य सर्वार्थोऽधिकरणस्य तत्र श्रुनत्वा दित्याद्युक्तिः न हेत्व भिधानपरा । जीवन्मुक्तप्राणलिङ्गान्नेत्यशेष्येवंविधविषयचोद्यपरः । नोपासनाद्वैविध्यादिति हेतूक्तितत्परिहारपरेत्यभिप्रायादाह । एतदिति । अधिकरणार्थमुपसंहरति अत इति ।

Colophon :

इति श्रीमदात्रेयनागसूरिसूनुमेघनादारिविरचिते श्रीमद्रामानुजीयोत्तर-मीमांसाभाष्यभावप्रबोधने प्रथमाध्यायस्य प्रथमः पादः ।

R. No. 5778

Paper. 10½ × 9¼ inches. Foll. 8. Lines, 20 in a page. Devanāgarī. Good.

Transcribed in 1936-37 from a MS. of Adyar Library, Adyar.

(a) चण्डीरहस्यं by नीलकण्ठदीक्षितः

CAṆḌIRAHASYAM by Nīlakaṇṭhadīkṣita.

Foll. 1a—4b. Extent, 80 Granthas.

Stanzas in praise of Caṇḍi, an epithet of Durgā. The authorship is attributed to Nīlakaṇṭhadīkṣita.

Complete.

Beginning:

यच्छक्तिलेशसकृदर्पणपात्रभाव
मात्रादपि द्रुहिणशौरिमहेश्वराणाम् ।
प्राप्तो यदि श्रुतिशतैः परमात्मभाव-
स्तामम्ब देवि भवतीं किमिति स्तुवन्तु ॥

कृत्वा मुखं पशुपतिर्भवती किलैकां
निर्माति पालयति हन्ति जगन्ति देवः ।
तज्जामिता विपरीतस्तकृते तमेव
शम्भुं मुखं कृतवती भवतीति मन्ये ॥

End:

अभ्यर्थनीयमखिलं भवदाश्रिताना
मभ्यार्थितं प्रथममेवहि देवसङ्घैः ।
अम्ब स्मरन् सफलयाम्यवशिष्टमायुः
रङ्गानिवे भुवनमङ्गलमङ्गलानि ॥

(b) रामायणसारसंग्रहरघुवीरस्तवः ।

RĀMĀYAṆASĀRASAṄGRAHARAGHUVĪRASTAVAḤ.

Foll. 4b—8a. Foll. 8b is left blank. Extent, 80 Granthas.

This book contains stanzas in praise of Rāma and the stanzas give a summary of the Rāmāyaṇa. The author is the famous Nīlakaṇṭhadīkṣita, the grandson of Accāndīkṣita, brother of the famous Appayadīkṣita.

Beginning :

वेधोवितीर्णविशदात्मविवर्तनां स्वा-
मप्रस्मरन् रघुपते कुलतन्तुमस्य ।
मन्ये ररक्षिथ विर्भीषणमप्रमत्तो
निः शेषयन्नपि कुलं रजनीचराणाम् ॥

यज्ञं ररक्षिथ मुनेर्यदि कौशिकस्य
यज्ञात्मनस्तव तुलां विदुरात्मरक्षाम् ।
कीर्तिं यदीच्छसि कृतार्थय मामनाथं
काकुत्स्थ वीर करुणामसृणैरपाङ्गैः ॥

End :

सत्यप्रियाय शरणागतवत्सलाय
सर्वापदां प्रशमनाय सकृत् प्रपत्त्या ।
श्रीरामनामपरिपूतजगत्त्रयाय
सीतासखाय पुरुषाय नमो नमस्ते ॥

Colophon :

इति श्रीमद्भरद्वाजकुलजलधिकौस्तुभश्रीकण्ठमतप्रतिष्ठापनाचार्य चतुरधिकशतप्रबन्धनिर्वाहकश्रीमन्महाव्रतयाजिश्रीमदप्पयदीक्षितसोदर्य श्रीमदाच्चा दीक्षितपौत्रेण नारायणदीक्षितात्मजेन श्रीभूमिदेवीगर्भसंभवेन श्रीनीलकण्ठ-दीक्षितेन विरचितासु कृतिषु रामायणसारसंग्रहरघुवीरस्तवस्समाप्तः ॥

R. No. 5779

Paper. 10¼ × 9¼ inches. Foll. 22. Lines, 20 in a page. Devanāgarī. Good. Extent, 660 Granthas.

Transcribed in 1936-37 from a MS. of Śrī Sarvajñācārya Avargal, Hospet, Bellary district.

हनुमद्विजयसमवाकारः by कृष्णावधूतः

HANUMADVIJAYASAMAVĀKĀRAḤ by Kṛṣṇāvadhūta.

This is a Samavākāra, one of the ten types of Sanskrit dramas. In this work, the success of Hanumān over the demons in Laṅkā is described. From the colophon, it appears that the author Kṛṣṇāvadhūta had proficiency in six languages.

Complete.

Beginning :

म—ततो महिरावणो भूलङ्कामागत्य रावणादिष्टः पातालं ययौ । ततः पल्प्रासमया दूतमुखनो विदितोदन्तेन विभीषणेनोपदिष्टो हनुमान वालेन प्राकारं विरच्य शिबिरमुखे तिष्ठति ।

मात—किमत्युपदेशः ।

म—महिरावणो रावणचोदितस्सन् रामलक्ष्मणौ पाताललङ्कां नीत्वा भद्रकाल्यै बलिं हास्यति त्वं सर्वथारक्षेति । तद्वयमपीतो निष्क्रम्य हनुमत्संमुखमेव गच्छामः इतित्थं परिक्रामयति । आयुष्मन् कथमत्रैव विभीषणः ।

म—न केवलं विभीषणः । अपितु मायया सह ।

* * * *

Colophon :

श्रीघटिकाशतषड्भाषासरसकविताचरणचणस्य कृष्णावधूतकवेः कृतौ श्रीहनुमद्विजयसमवाकारे प्रथमोऽङ्कः ।

End :

विभीषणः—तथापीदमस्तु भरतवाक्यम् ।

मन्दारमालामकरन्दलोभ-
भ्राम्यन्मिलिन्दावलिराजमाने ।
रक्षोधिपस्य स्फुरदुत्तमाङ्गे
रामस्त्ववामाङ्घ्रितलं निधत्ताम् ॥

अपिच—

चिरंजीव श्रीमन् भवनिखिलपृथ्वी भरमहा-
सुरद्विड्विध्वंसप्रणय रघुनाथप्रियतम ।

हनुमान्—

चिरं रामः क्षोणीमवतु जनकापत्यसहितः ।
समुद्रान्तां दान्तानृषिवत्नरान् वानरगणान् ॥
....

वैमानिकाः—

चिरं जीयाद्रामस्तदनुज उदारः क्षितिसुता
हनूमान् सर्वारिक्षपणनिपुणो मारुतिरपि ।
अयं राजा भूयाद्रघुपतिसखो राक्षसपुरे
प्रवर्तन्तां सन्तः सुखसुखमिमे तीर्णविपदः ।
इति निष्क्रान्तास्सर्वे ।

Colophon :

श्रीघटिकाशतषड्भाषासरसकविताचरणचणस्य कृष्णावधूतकवेः कृतौ श्रीहनमद्विजयसमवाकारे तृतीयोऽङ्कः ॥

R. No. 5780

Paper. 10¾ × 9½ inches. Foll. 76. Lines, 20 in a page. Devanāgarī. Good. Extent, 1,854 Granthas.

Restored in 1936-37 from D. No. 11965.

गीतगोविन्दम् - संग्रहदीपिकाव्याख्यासहितम् ।

GĪTAGOVINDAM with the commentary Saṅgrahadīpikā.

Foll. 1a—75a. Foll. 75b-76 are left blank.
Complete.

R. No. 5781

Palm leaf. 14¾ × 1½ inches. Foll. 100. Lines, 9 in a page. Grantha. Slightly injured. Extent, 2,600 Granthas.

Purchased in 1936-37 from Śrī K. Raṅgasami Iyengar Avargal, South Śiruvalur, Tindivanam taluk.

रामायणव्याख्या by ईश्वरदीक्षितः ।

RĀMĀYAṆAVYĀKHYĀ by Īśvaradīkṣita.

Almost complete.

Same work as that described under R. No. 4773 ante.

R. No. 5782

Palm leaf. 14 × 1½ inches. Foll. 23. Lines, 8 in a page. Grantha. Slightly injured.

Purchased in 1936-37 from Śrī K. Raṅgasami Iyengar Avargal, South Śiruvalur, Tindivanam taluk.

पदार्थधर्मसंग्रहः by प्रशस्तपादः

PADĀRTHADHARMASAṄGRAHAḤ by Praśastapāda.

Foll. 4a–5b. Extent, 35 Granthas.

Same work as that described under R. No. 1553 (a).

Incomplete.

Foll. 1–3 contains Tarkaviṣayaḥ.

(b) पदार्थधर्मसंग्रहव्याख्या by जगदीशः

PADĀRTHADHARMASAṄGRAHAVYĀKHYĀ by Jagadīśa

Foll. 6a—23b. Extent, 400 Granthas.

This is a commentary on the Padārthadharmasaṅgraha by Jagadīśa tarkālaṅkāra, the author of Tattvacintāmaṇidīdhitiprakāśikā.

Incomplete.

Beginning :

कणभक्षमुनेः पक्षरक्षाविन्यस्तवासनाः ।
सूक्तिं श्रीजगदीशस्य चिन्तयन्तु विचक्षणाः ।

ग्रन्थारंभे विघ्नविघाताय कृतस्येश्वरादिप्रणामस्य शिष्याणां शिक्षार्थमादौ निबन्धपूर्वकं प्रवृत्यङ्गमभिधेयं दर्शयति प्रशस्तपादाचार्यः प्रणम्येति, ईश्वरं प्रणम्य ततः ईश्वरप्रणामादनु पश्चात् कणादं प्रणम्येत्यन्वयः ।

End :

एवमश्वत्थदलादेः कम्पः स्पर्शवेगवद्द्रव्याभिघातजः कर्म विशेषत्वात् दण्डाभिहत . . . वत् ।

इत्यादिप्रयोगसंभवादिति भावः । तिर्यग्गमनेति, तिर्यग्गमनं स्वभावो अस्य ।

R. No. 5783

Palm leaf. 18¼ × 1¼ inches. Foll. 137. Lines, 7 in a page. Grantha. Slightly injured. Extent, 3,562 Granthas.

Purchased in 1936–37 from Śrī K. Raṅgasami Iyengar Avargal, South Śiruvalur, Tindivanam taluk.

अनर्घराघवव्याख्या by हरिहरः

ANARGHARĀGHAVAVYĀKHYĀ by Harihara.

Same work as that described under D. No. 12445.

Complete.

R. No. 5784

Palm leaf. 14⅞ × 1½ inches. Foll. 25. Lines, 5 in a page. Grantha. Injured. Extent, 5.0 Granthas, printed.

Purchased in 1936–37 from Śrī K. Raṅgāswami Ayyangar, South Siruvalūr, Tindivanam.

भर्तृहरिसुभाषितम् by भर्तृहरि ।

BHARTṚHARISUBHĀṢITAM by Bhartṛhari

Contains Sṛṅgāraśataka complete.

Same work as that described under D. No. 12080.

R. No. 5785

Palm leaf. 18 × 1½ inches. Foll. 130. Lines, 8 in a page. Grantha. Slightly injured. Extent, 4,160 Granthas.

Purchased in 1936–37 from Śrī K. Rangasami Ayyangar Avargal, South Śiruvalur, Tiṇḍivanam taluk.

अनर्घराघवव्याख्या पञ्चिका by विष्णुभट्टः

ANARGHARĀGHAVAVYĀKHYĀ— by Viṣṇubhaṭṭa.

Same work as that described under D. No. 12461.

Complete.

R. No. 5786

Palm leaf. 17 × 1½ inches. Foll. 30. Lines, 7 in a page. Telugu. Much injured. Extent, 1,400 Granthas.

Purchased in 1936–37 from Śrī K. Raṅgasami Ayyangar Avargal, South Śiruvalur, Tiṇḍivanam taluk.

श्लोकवार्तिकव्याख्या न्यायरत्नाकरः by पार्थसारथिमिश्रः ।

ŚLOKAVĀRTIKAVYĀKHYĀ—NYĀYARATNĀKARAḤ by Pārthasārathimiśra.

This is a commentary on the Ślokavārtika of Kumārila Bhaṭṭa by Pārthasārathimiśra, the author of Śāstradīpikā.

Wants the beginning and end.

Beginning :

तेन श्रोत्रस्य तद्वत्येव व्यापरणं न स्यात् । प्रत्युत विघात एव शब्दगतेनानुवादेन वृत्तस्स्यादित्याह । नानुवादेति । पादत्रयेण किञ्चित् प्रतिपादनशब्दस्यापत्तिर्दूरं गच्छेदित्याह । प्रतिघातमिति, कारणमाह तद्गतमिति ।

* * * *

Colophon :

इति महोपाध्यायपार्थसारथिमिश्रविरचिते न्यायरत्नाकरे अर्थापत्ति-प्रकरणं समाप्तम् ।

End :

प्रमित इति भवतु, प्रमिते प्रवृत्तिः तथापि किमित्यप्रामाण्यमत आह । परिच्छेदेति । अगृहीतग्रहणं परिच्छेदसंस्कर्ता नास्तीति चोदयति । यदिति । परिहरति यावानिति । ननु संस्कारजन्यस्मृतिपदात् पदार्थस्मृतिरनुत्र ।

R. No. 5787

Palm leaf. 15 × 1¼ inches. Foll. 105. Lines, 7 in a page. Telugu. Slightly injured. Extent, 2,730 Granthas.

Purchased in 1936-37 from Śrī K. Raṅgasami Ayyangar Avargal, South Siruvalur, Tiṇḍivanam taluk.

किरणावलीव्याख्या by रुचिदत्तः ।

KIRAṆĀVALĪVYĀKHYĀ by Rucidatta.

Same work as that described under R. No. 1541.

Incomplete.

R. No. 5788

Palm leaf. 14½ × 1¼ inches. Foll. 19. Lines, 7 in a page. Grantha. Good. Extent, 400 Granthas. Printed.

Purchased in 1936-37 from Śrī K. Raṅgasami Ayyangar Avargal, South Siruvalur, Tiṇḍivanam taluk.

तान्त्रिकमीमांसा by अप्पयदीक्षितः ।

TĀNTRIKAMĪMĀṀSĀ by Appayadīkṣita.

A treatise in which Appayadīkṣita states, that priests employed in Śiva temples offering worship to Lord Śiva according to Śaivāgamas, are not Brahmins. The author concludes that Āgamas, regulating the worship in temples are not authoritative.

Complete.

Beginning :

यन्मयं निखिलं विश्वं ब्रह्मविष्णुशिवादिकम् ।
सर्ववेदान्तवेद्योयस्स हरिः श्रेयसेऽस्तु वः ।
अभिप्रवादात् साङ्कर्ये साम्प्रतं सामुपस्थिते ।
कुर्वे तान्त्रिकमीमांसां वैदिकानामहं मुदे ॥

शिवद्विजस्याध्ययनाद्यधिकोराऽस्तिवा नवेति मीमांस्यते । तावत्तदर्थमपि चिन्त्यते । ब्राह्मणं चोपनयनमध्याप्याङ्गमुष्यच ।

किं तावत्प्राप्तमस्तीति ब्राह्मणं ब्राह्मणोद्भवात् ॥

End :

इयं तान्त्रिकमीमांसा स्मृत्यादिवचनोज्वला ।

कृता लोकोपकाराय सज्जनैरभिनन्द्यताम् ॥

सन्तोऽपि दोषाः क्षन्तव्याः सन्तोषगुणतत्पराः ।

सञ्चरन्तः स्खलन्त्येव सम . . . ।

यदुक्तं शिवपारम्यं शैवग्रन्थेषु केषु चित् ।

नहि मे हार्दभावोऽसौ यतस्सर्वपरो हरिः ॥

Colophon :

इति श्रीमद्भरद्वाजकुलजलधिकौस्तुभश्रीमदद्वैतविद्याचार्यश्रीमद्विश्वजियाजि श्रीरङ्गराजाध्वरिवरसूनोरप्पयदीक्षितस्य कृतौ तान्त्रिकमीमांसा समाप्ता ।

R. No. 5789

Palm leaf. 16 × 1¾ inches. Foll. 70. Lines, 7 in a page. Grantha. Slightly injured. Extent, 1,400 Granthas.

Purchased in 1936-37 from Śrī K. Raṅgasami Ayyangar Avargal, South Ś.ruvalur, Tiṇḍivanam taluk.

रहस्यत्रयसारश्लोकद्राविडव्याख्या ।

RAHASYATRAYASĀRAŚLOKADRĀVIḌAVYĀKHYĀ.

See Tamil Part for description.

Incomplete.

R. No. 5790

Palm leaf. 15 × 1¼ inches. Foll. 108. Lines, 7 in a page. Grantha. Slightly injured. Extent, 3,024 Granthas.

Purchased in 1936-37 from Śrī K. Raṅgasami Ayyangar Avargal, South Ś.ruvalur, Tiṇḍivanam taluk.

तत्त्वचिन्तामणिदीधितिव्याख्या - भवानन्दीया ।

TATTVACINTĀMAṆIDĪDHITIVYĀKHYĀ—BHAVĀNANDĪYĀ.

Same work as that described under D. No. 4092.

Incomplete.

R. No. 5791

Palm leaf. 16 × 1½ inches. Foll. 155. Line, 8 on a page. Grantha. Slightly injured. Extent, 4,960 Granthas.

Purchased in 1936-37 from Śrī K. Raṅgasami Ayyangar Avargal, South Siruvalur, Tiṇḍivanam taluk.

बोधायनप्रयोगादर्शः by कनकसभापतिः

BODHĀYANAPRAYOGĀDARŚAḤ by Kanakasabhāpati.

Same work as that described under R. No. 1619.

Complete.

R. No. 5792

Palm leaf. 14½ × 1½ inches. Foll. 70. Lines, 12 in a page. Grantha. Much injured. Extent, 3,360 Granthas.

Purchased in 1936-37 from Śrī K. Raṅgasami Ayyangar Avargal, South Siruvalur, Tiṇḍivanam taluk.

न्यायबिन्दुः by पायगोण्डवैद्यनाथः

NYĀYABINDUḤ by Pāyagoṇḍavaidyanātha.

A treatise on Mīmāṁsā principles interpreted in accordance with Vaiyākaraṇa views.

Incomplete and wants 3 leaves in the beginning.

Beginning :

याजनवदर्थज्ञानज्ञेयाध्ययनफलं तत्रार्थवादेभ्यो यद्यपि यथाश्रुतेभ्यो न संभवति तथापि तात्पर्यात् लक्षणया स्तावकत्वेन सन्निहितविध्ये . . . भवतीति युक्तम् । धर्मप्रामाण्यमिति सिद्धान्तः ।

End :

पुनर्विनियोगवचनं तु परिसंख्यार्थम् । लिङ्गादि अश्वरशना . . . . . . स्तन्निवृत्यर्थं सा चैकत्र विधावन्यत्र मन्त्राकाङ्क्षामूलकलैङ्गिकविध्यकल्पनादार्थिकीति न श्रुतहान्यश्रुत ।

R. No. 5793

Palm leaf. 16 × 1½ inches. Foll. 75. Lines, 7 on a page. Telugu. Injured. Extent, 2,100 Granthas.

Purchased in 1937-38 from Śrī K. Raṅgasami Ayyangar Avargal, South Siruvalur, Tiṇḍivanam taluk.

वेदार्थतत्त्वनिर्णयः by लिङ्गाध्वरीन्द्रः
VEDĀRTHATATTVANIRṆAYAḤ by Liṅgādhvarīndra.

In this work, Liṅgādhvarīndra, the son of Govindādhvarīndra, states that the truth contained in some of the passages of the Veda.

Wants beginning in first Paricchoda and wants end in the 2nd Paricchoda.

Beginning :

नमो रोहितायेत्यादि नवमं यजुः । रोहिताय लोहितवर्णाय यद्वा रोशब्दस्य वाचकत्वाद्रूपः तस्मै हिताय तत्र वा निहिताय स्थपतये प्रभवे विग्रहादीनां वा कर्त्रे, यथा

* * * *

Colophon :

इति श्रीमदद्वैतविद्याचार्यसाग्निचित्यसर्वतोमुखातिरात्रसाग्निचित्याप्तवाजपेययाजिगोविन्दाध्वरीन्द्रतनय लिङ्गाध्वरीन्द्रविरचिते वेदार्थतत्त्वनिर्णये प्रथमः परिच्छेदः ।

* * * *

सर्वमिदं ब्रह्मविष्णुरुद्र . . . . . इति तिनां जनितादिवो भुविता पृथिव्याः जनिताग्नेर्जनिता सूर्यस्य जनितेन्द्रस्य जनितोतविष्णोरिति

* * * *

अहमस्मीति तस्मिंस्त्वयि किं वीर्यमिति अपीदं सर्वं माददीय यादिदं पृथिव्यामिति तस्मै तृणं निगदावेतगोतस्येति

R. No. 5794

Paper. 9¼ × 3⅜ inches. Foll. 24. Lines, 7 on a page. Devanāgarī. Good. Extent, 246 Granthas. Printed.

Purchased in 1936–37 from Śrī P. Veṅkaṭaramaṇācārya, 22, Raja Hanumantalala Street, Triplicane, Madras.

कर्मनिर्णयः by आनन्दतीर्थः

KARMANIRṆAYAḤ by Ānandatīrtha.

In this work, Ānandatīrtha shows that all the various passages, which enjoin the performance of acts to propitiate Gods like Indra, Varuṇa and others, refer to God Viṣṇu alone.

Complete.

foll. 24*b* and 25 contains Tattvanirṇaya—Incomplete.

R. No. 5795

Paper. 12 × 5¼ inches. Foll. 15. Lines, 11 on a page. Devanāgarī. Injured. Extent, 412 Granthas. Not printed.

Purchased in 1936–37 from Śrī P. Veṅkaṭaramaṇācariar, 22, Raja Hanumantalala Street, Triplicane, Madras.

षट्प्रश्नोपनिषत्खण्डार्थः ।

ṢAṬPRAŚNOPANIṢATKHAṆḌĀRTHAḤ.

In this work, the idea, contained in the "ṣaṭ praśna" upaniṣad, is given in brief.

Complete.

Beginning :

श्रीरङ्गविठ्ठलं नत्वा सर्वज्ञादीन् गुरूनपि ।
षट्प्रश्नाख्योपनिषट्टीकार्थो विनिगद्यते ॥

इह खलु संसारपारावारे विनिपतितमधिकारिणं जनं जननी तनयमिव परमात्मतत्वज्ञानप्लवेनोद्धर्तुं प्रवृत्तेयमाथर्वणीब्राह्मणोपनिषत् । अस्या उपनिषदो वासुदेवो मुख्यतया प्रतिपाद्यो देवता । प्राणादयस्तु तच्छेषतया तथेतिज्ञेयम् ।

End :

कोहि नामैव मुपकुर्यादिति । एवमाख्यायिकां समाप्य वेदपुरुषः शिष्यशिक्षार्थमाह—नमः परमऋषिभ्यः । पिप्पलादि . : इति द्विर्वचनमादरार्थमित्यशेष मतिमङ्गलमिति । इति षष्ठप्रश्नप्रतिवचनम् ।

Colophon :

इति षट्प्रश्नोपनिषत्खण्डार्थः समाप्तः ।

Scribe adds :

दुर्मुखिनामसंवत्सर कार्तिकशुद्धदशमीभानुवासरे एतल्लेखनं संपूर्णम् ।

R. No. 5796

Paper. 12¼ × 4 inches. Foll. 5. Lines, 8 on a page. Devanāgari. Injured. Extent, 125 Granthas. Printed.

Purchased in 1936–37 from Śri P. Veṅkaṭaramaṇācar, 22, Raja Hanumantalala Street, Triplicane, Madras.

तन्त्रसारसंग्रहः by आनन्दतीर्थः ।

TANTRASĀRASAṄGRAHAḤ by Ānandatīrtha.

Same work as that described under R. No. 573 (l).

Complete 1 and 2 Adhyāyas.

R. No. 5797

Paper. 12 × 5¼ inches. Foll. 47. Lines, 13 on a page. Devanāgari. Much injured. Extent, 1,794 Granthas. Printed.

Purchased in 1936–37 from Śri P. Veṅkaṭaramaṇācar, 22, Raja Hanumantalala Street, Triplicane, Madras.

महाभारतम् by व्यासः

MAHĀBHĀRATAM by Vyāsa.

Same work as that described under D. No. 1915.

Complete Śalyaparvan.

R. No. 5798

Paper. 12¾ × 4¾ inches. Foll. 40. Lines, 11 on a page. Devanāgari. Much injured. Extent, 1,485 Granthas.

Purchased in 1936–37 from Śri P. Veṅkaṭaramaṇācar, 22, Raja Hanumantalala Street, Triplicane, Madras.

तत्त्वप्रकाशिकाव्याख्या - भावबोधः by रघूत्तमयतिः ।

TATTVAPRAKĀŚIKĀVYĀKHYĀ—BHĀVABODHAḤ by Raghūttamayati.

Same work as that described under R. No. 878 *ante*.

Contains 3rd and 4th Padas in the first Adhyāya.

Beginning :

तनत्वन ततोभिन्नब्रह्मणो न संभवति । चेतनस्य जडात्यन्तभिन्नस्य जडात्मना भवनस्य यतोदेवदत्तघटादावन्यत्रादृष्टिरिति विकारकारण मेवेति तद्पो सृजतेत्यादौ तेजः प्रभृतिभूतानामब्वादिकं प्रत्युपादानत्वस्या विवक्षितत्वादि ति भावः ।

End :

अत्र पादे विरोधि सर्वं वाग्दृष्य कारणस्तीनिषेधेनापृथक् समन्वयार्थानि स्थानान्येतानि सर्वं इत्यनुव्याख्यान व्यक्तः "कर्म वाक्यैश्च वाक्य एको मितात्मकः" अवान्तरंकारणश्च प्रकृतिः शून्यमेव च" इति संग्रहे चोक्तन्यायेन प्रत्येकमेकैकाधिकरण मेकैका पेटिकेति ज्ञेयम्।

Colophon :

इति श्रीमद्रघुवर्यतीर्थ पूज्यपाद शिष्य रघूत्तमयतिकृते तत्त्वप्रकाशिका भावबोधे प्रथमाध्यायस्य चतुर्थः पादः।

R. No. **5799**

Paper. 12¼ × 4¼ inches. Foll. 6. Lines, 11 on a page. Devanāgarī. Slightly injured. Extent, 199 Granthas.

Purchased in 1936-37 from Śrī P. Veṅkaṭaramaṇācar, 22, Raja Hanumantalala Street, Triplicane, Madras.

ब्रह्मसूत्रभाष्यव्याख्या – दीपिका by जगन्नाथयतिः

BRAHMASŪTRABHĀṢYAVYĀKHYĀ–DĪPIKĀ by Jagannātha-yati.

Same work as that described under D. No. 4814.

R. No. **5800**

Paper. 10½ × 3 inches. Foll. 161. Lines, 9 on a page. Devanāgarī. Injured. Extant, 4,350 Granthas.

Purchased in 1936-37 from Śrī P. Veṅkaṭaramaṇācar, Hanumantalala Street, Triplicane, Madras.

भगवद्गीताभाष्यटीका—प्रमेयदीपिका—by Jayatīrtha.

BHAGAVADGĪTĀBHĀṢYAṬĪKĀ–PRAMEYADĪPIKĀ.

Same work as that described under R. No. 5811.

Complete.

R. No. **5801**

Paper. 12 × 5 inches. Foll. 12. Lines, 10 on a page. Devanāgarī. Good. Extent, 427 Granthas.

Purchased in 1936-37 from Śrī Veṅkaṭaramaṇācar, Hanumantalala Street, Triplicane, Madras.

तत्त्वसंख्यानविवरणव्याख्या by व्यासतीर्थः

TATTVASAṄKHYĀNAVIVARAṆAVYĀKHYĀ by Vyāsatīrtha.

Similar to the work described under R. No. 3928 (m).

Complete.

Beginning :

लक्ष्मीपते पदद्वन्द्वं नत्वा गुरुकृपाबलात् ।
व्याकरिष्ये यथाबोधं तत्वसङ्ख्यानपञ्चिकाम् ॥

इह खलु सुखमेव मे स्याद् दुःखं मनागपि माभूदिति निखिला-पेक्षितमोक्षस्य भगवत्स्वातन्त्र्यज्ञानसाध्यत्वात्तदर्थं प्रकृतं तत्वसङ्ख्यानं व्याचिख्यासुः जयतीर्थपूज्यचरणः प्रारिप्सितसमाप्त्यादिप्रयोजनमविगीत शिष्टाचारप्राप्तं विशिष्टेष्टदेवतानतिस्तुतिलक्षणं मङ्गलमनुष्ठाय शिष्यशिक्ष-णाय ग्रन्थे निबध्नन् शिष्यावधानाय चिकीर्षितं प्रतिजानीते । लक्ष्मीप-तेरिति ।

End :

नचैवं नवनवसुविशेषेत्यादिविरोध इति वाच्यम् ।
अभिव्यक्तत्वाभिप्रायेण तस्योपपत्ते । विस्तृतं चैतदन्यत्रेति दिक् ।
यद्वा रमायाः प्रकृतिसंबन्धाभावे हि ज्ञानाभावत्वादिति भावः ।

कृतिप्रतिपादित मगुणवन्त मन्तोपि स्तुवन् तत्प्रीतिं प्रार्थयते । पद्मेति ।

कमलाकमलोद्भूतमुखंयस्याखिलं जगत् ।
परतन्त्रं स्वतन्त्रस्य वशे सप्रीयतां हरिः ॥
तत्वसङ्ख्यानटीकायाः पञ्चिका शक्तिमात्रतः ।
भूयात् कृता पि सुप्रीत्य श्रीमन्माधवमध्वयोः ॥
द्वैपायनप्रसादेन गुरूणांच कृपाबलात् ।
तत्त्वसङ्कणनाव्याख्या व्याख्यागोचरतामियात् ॥

Colophon :

इति श्रीतत्त्वसङ्ख्यानविवरणं व्यासतीर्थविरचितं समाप्तम् ।

R. No. 5802

Paper. 11¼ × 5 inches. Foll. 27. Lines, 13 on a page. Devanāgari. Good. Extent, 800 Granthas.

Purchased in 1936-37 from Śrī Veṅkaṭaramaṇācar, Hanumantalala Street, Triplicane, Madras.

प्रमाणपद्धतिः जयतीर्थविरचिता

PRAMĀṆAPADDHATIḤ by Jayatirtha.

Same work as that described under D. No. 4803.

R. No. 5803

Paper. 10 × 5¼ inches. Foll. 7. Lines, 15 on a page. Devanāgari. Not good.

Purchased in 1936-37 from Śrī Veṅkaṭaramaṇācariar, Hanumantalala Street, Triplicane, Madras.

(a) काठकोपनिषद्.

KĀṬHAKŌPANIṢAD.

Foll. 1a-4a, Extent, 100 granthas.

Same work as that described under D. No. 334.

Complete.

(b) काठकोपनिषद्भाष्यम्—आनन्दतीर्थविरचितम्

KĀṬHAKŌPANIṢADBHĀṢYAM by Ānandatirtha.

Foll. 4a—7a. Extent, 100 granthas.

Same work as that described under D. No. 348.

R. No. 5804

Paper. 12 × 4½ inches. Foll. 32. Lines, 9 on a page. Devanāgari. Not good. Extent, 710 granthas.

Purchased in 1936-37 from Śrī Veṅkaṭaramaṇācār, Hanumantalala Street, Triplicane, Madras.

ब्रह्मसूत्रभाष्यव्याख्या—तत्वप्रकाशिका—जयतीर्थप्रणीता

BRAHMASŪTRABHĀṢYAVYĀKHYĀ—TATTVAPRAKĀŚIKĀ by Jayatirtha.

Same work as that described under R. No. 1148.

Contains 2nd and 3rd Pādas of 1st Adhyāya—3rd incomplete.

R. No. 5805

Paper. 12 × 4 inches. Foll. 57. Lines, 9 on a page. Devanāgari. Good. Extent, 1,000 granthas.

Purchased in 1936-37 from Śrī Veṅkaṭaramaṇācariar, Hanumantalala Street, Triplicane, Madras.

भगवद्गीतातात्पर्यनिर्णयः—आनन्दतीर्थप्रणीतः

BHAGAVADGĪTĀTĀTPARYANIRṆAYAḤ by Ānandatīrtha.

Same work as that described under R. No. 455.

Complete.

R. No. 5806

Paper. 12 × 4¼ inches. Foll. 139. Lines, 8 on a page. Dēvanāgarī. Good. Extent, 3,350 Granthas. Printed.

Purchased in 1936-37 from Śrī Veṅkaṭaramaṇācar, Hanumantalala Street, Triplicane, Madras.

ब्रह्मसूत्रभाष्यटीकाविवृतिः—तात्पर्यचन्द्रिका by व्यासयतिः

BRAHMASŪTRABHĀṢYAṬĪKĀVIVṚTIḤ—TĀTPARYACANDRIKĀ by Vyāsayati.

Same work as that described under R. No. 4110 (*b*).

2nd Adhyāya complete.

Beginning :

पूर्वेणोक्ते समन्वयेऽनेन विरोधः परिह्रियत इत्यध्याययो र्हेतुहेतुमद्भावलक्षणा सङ्गतिः। पूर्वोहि एतन्निरसनीयाविरोधशङ्काविषयभूतसमन्वयोपस्थापकतयाऽस्यहेतुः। अयं वा विरोधनिरासेन समन्वयस्थैर्यसाधकत्वात्तस्यहेतुः। तथाचसमन्वयाक्षेपसमाधानार्थत्वादस्य तदनन्तरता युक्ता।

युक्तिभिः समयैः शुद्धवेदैर्युक्त्युपबृंहितैः।
वेदैश्चाप्यविरोधोत्र क्रमात् पादेषु कीर्त्यते ॥

अत्राद्यपादे युक्त्यविरोधः। द्वितीये लौकिकार्थगोचरबहुजनपरिगृहीतवाक्यसन्दर्भरूपसमयाविरोधः। तृतीये केवलश्रुत्यविरोधः। चतुर्थे सयुक्तिकश्रुत्यविरोधः।

Colophon :

इति श्रीमद्व्यासयतिना विरचितायां श्रीमद्भाष्यतात्पर्यचन्द्रिकायां द्वितीयाध्यायस्य प्रथमः पादः।

End :

किञ्च सौत्रेण भौमशब्देन तैजसत्वाद्युपलक्षणे यथाशाब्दमितरयोरिति व्यर्थं। मांसादित्यादिशब्दोक्तलोहितमज्जारूप दृष्टान्तगताप्यतेजसत्वयोरपि भौमशब्देनैव लाभात्। अनुपलक्षणे च मांसादित्यादिशब्दोक्तवाग्रूप दार्ष्टान्तिकस्य तैजसत्वं न सिध्येदिति यत्किञ्चिदेतत्। केचित्तु अनेन जीवेनेति श्रुतेः जीवविशेषहिरण्यगर्भकर्तृकं नामरूपव्याकरणमिति पूर्वपक्षयन्ति। तन्न। जीवशब्दमात्रेण हिरण्यगर्भकर्तृकत्वं पूर्वमेवदूषितं।

R. No. 5809

Paper. 10½ × 4 inches. Foll. 316. Lines, 10 on a page. Devanāgarī. Injured. Extent, 6,320 Granthas.

Purchased in 1936–37 from Śrī Veṅkaṭaramaṇācar, Hanumantalala Street, Triplicane, Madras.

भारततात्पर्यनिर्णयः टिप्पणीसहितः ।

BHĀRATATATPARYANIRṆAYAḤ with Ṭippaṇī.

The text is written by Ānandatīrtha and the commentary by Varadarāja.

Same text as that described under D. No. 4824 and commentary described under D. No. 4830.

R. No. 5810

Paper. 10¼ × 5½ inches. Foll. 36. Lines, 13 on a page. Devanāgarī. Good. Extent, 936 Granthas.

Purchased in 1936–37 from Śrī Veṅkaṭaramaṇācar, Hanumantalala Street, Triplicane, Madras.

यमकभारतटीका by यदुपतिः

YAMAKABHĀRATAṬĪKĀ by Yadupati.

Same work as that described under D. No. 11890.

Wherein see for the beginning.

Complete.

End :

सुरशिखामणिमध्वविनिर्मितं
यमकभारत मिहैकदेशतः ।
विवरितुं नहि शक्य मथापित-
त्करुणया कृतिरीषदियं मम ॥
व्यासं सर्वगुणावासं वासवीनन्दनं विभुम् ।
श्रीनिवासं सदा वन्दे भासमानं हृदम्बरे ॥

Colophon :

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितस्यश्रीमद्यमकभारत तात्पर्यनिर्णयस्य टीका श्रीमद्वेदेशतीर्थपूज्यपादशिष्येण यदुपतिना विरचिता समाप्ता ।

Scribe adds:

श्रीनृसिंहार्यतनूजेन रामचन्द्रेण सेविना ।
लिखिता यमकस्यापि व्यख्या श्रीनिर्मलाशुभा ॥
बिंबमूर्तिः श्रीनिवासः प्रीतो भवतु सर्वदा ।
लेखनेन श्रमो यस्तु सफलं भवति ध्रुवम् ॥

आनन्दनाम संवत्सर आषाढमास . . . . . . चतुर्थ्यामेतल्लेखनं संपूर्णम् ॥

R. No. 5811

Paper. 10¾ × 4 inches. Foll. 195. Lines, 11 on a page. Devanāgarī. Good. Extent, 4,350 Granthas.

Purchased in 1936-37 from Śrī Veṅkaṭaramaṇācar, Hanumantalala Street, Triplicane, Madras.

भगवद्गीताभाष्यटीका— प्रमेयदीपिका—जयतीर्थप्रणीता

BHAGAVADGĪTĀBHĀṢYAṬĪKĀ—PRAMEYADĪPIKĀ by Jayatīrtha.

A commentary on Ānandatīrtha's Bhagavadgītābhāṣya by Jayatīrtha which work has been described under D. No. 2080.

Complete.

Beginning :

गुणगणनिलयं पतिं रमायाः
जगदघदहनं च वासवीसूनुम् ।
मुनिकुलतिलकं च पूर्णबोधं
गुरुमपि परमगुरुं च मे वन्दे ॥
आनन्दतीर्थ भगवत्पादाचार्य विनिर्मितम् ।
व्याख्यास्ये भगवद्गीताभाष्यं तत्करुणाबलात् ॥

प्रारिप्सितविघ्नविघातादिप्रयोजनं समुचितविशिष्टेष्टदेवतागुरुप्रणामं ग्रंथारंभप्रतिज्ञां चादौ निबध्नाति भगवान् भाष्यकारः । देवमिति । अत्र देवशब्दो देवताशब्दपर्यायः । प्रतिपाद्यमाह । सन्निधानाद्भगवद्गीताया इति लभ्यते । तेनेदानी नारायणस्य प्रणामे समुचिततामाचष्टे । अज्ञान पारतन्त्र्यादिभिः सर्वदोषैः विशेषेण सर्वदा सर्वात्मना वर्जितं परितो देशतः कालतः गुणतश्च पूर्णमिति वैशिष्ट्यमाचष्टे ।

End :

कथमिति । अस्मिन् शास्त्रे क्रियत इति शेषः । अशाब्दोऽयमर्थ इति चेन्न धर्मशब्दस्य स्वकार्यफलोपलक्षणत्वात् । एवमेव भगवता व्याख्यातत्वाच्चेत्याह—यस्त्विति । इदानीं समापितभाष्यो भगवानाचार्यो भाष्यनिर्माणस्य भगवत्प्रीतिमेव फलमाशास्ते । पूर्णेति । एतद्गीतामित्यनेन निरूपणमित्यनेन च सम्बध्यते । तेनेतिश्रवणाद्यदिति लभ्यते ।

करतलकलितामलकमिव
प्रभुणा येनेद मवगतं विश्वम् ।

स जयति जनकसुतायाः
कान्तः श्रीरघुनन्दनो देवः ॥

नमामि व्यासदासस्य पुण्यबुद्धेः पदाम्बुजे ।
नतामरशिरोरत्नराजिनीराजिते सदा ॥

अक्षोभ्यतीर्थगुरुणा शुकवच्छिक्षितस्य मे ।
वचोभिरमृतप्रायैः प्रीयन्तां सततं बुधाः ॥

Colophon :

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितस्य श्रीमद्गीताभाष्यस्य-टीकायां जयतीर्थमुनिविरचितायां प्रमेयदीपिकायां अष्टादशोऽध्यायः ॥

R. No. 5812

Paper. $10\frac{1}{4} \times 4$ inches. Foll. 41. Lines, 8 on a page. Devanāgarī. Good. Extent, 760 Granthas.

Purchased in 1936–37 from Śrī Veṅkaṭaramaṇācar, Hanumantalala Street, Triplicane, Madras.

प्रपञ्चमिथ्यात्वानुमानखण्डनपञ्चिकाव्याख्या—
भावप्रकाशिका—व्यासयतिप्रणीता

PRAPAÑCAMITHYĀTVĀNUMĀNAKHAṆḌANAPAÑCIKĀVYĀKHYĀ BHĀVAPRAKĀŚIKĀ by Vyāsayati.

Same work as that described under R. No. 3928 (*b*).
Wherein see for the beginning.

Complete.

End :

नाप्यभेदादि चिदात्मनेत्युक्त्या अभेदात्प्रसक्तो यो गुणगुणिभावाभावः सोपिनेति गुणग्रहणं कुर्वतोक्तमित्यर्थः । अभेदेपि विशेषबलात् गुणगुणिभावो भविष्यतीति भावः ।

अभीष्टफलदातारं शुकादिद्विजसेवितम् ।
भवाध्वाटनखिन्नोहं विष्णुमन्दारमाश्रये ॥

Colophon :

इति श्रीमद्ब्रह्मण्यपूज्यपादानां शिष्येण व्यासयतिना विरचिता प्रपञ्चमिथ्यात्वानुमानखण्डनपञ्चिका भावप्रकाशिका समाप्ता ।

R. No. 5813

Paper. 10 × 4 inches. Foll. 33. Lines, 8 on a page. Devanāgarī. Good. Extent, 512 Granthas.

Purchased in 1936-37 from Śrī Veṅkaṭaramaṇācār, Hanumantalala Street, Triplicane, Madras.

गयामाहात्म्यम् ।

GAYĀMĀHĀTMYAM.

Same work as that described under R. No. 2096.

Complete in 8 Adhyāyas.

R. No. 5814

Paper. 8½ × 4 inches. Foll. 81. Lines, 7-8 on a page. Devanāgarī. Good. Extent, 972 Granthas.

Purchased in 1936-37 from Śrī Veṅkaṭaramanācār, Hanumantalāla Street, Triplicane, Madras.

सृष्टिमुक्तावली—श्रीनिवासार्यविरचिता

SṚṢṬIMUKTĀVALĪ by Śrīnivāsārya.

A treatise on creation according to the Dvaita school by Śrīnivāsārya, son of Viṭhalārya and disciple of Tīrthārya.

Complete.

Beginning :

इन्दीवरदलश्यामं भैष्मीसत्या समन्वितम् ।
कृष्णं वन्दे पूर्णबोधमुनिहृत्पद्मसंस्थितम् ॥
श्रीविठलार्यपुत्रेण श्रीमत्तीर्थार्यसेविना ।
क्रियते श्रीनिवासेन सृष्टिमुक्तावलीशुभा ॥

क सृष्टिशास्त्राब्धिनिमग्नसृष्टि-
मुक्तावबोधोऽल्पधियो मम स्यात् ।
दूरेतु मुक्ताग्रथनं करिष्ये
तथापिसंस्मृत्य गुरोः पदाब्जम् ।

जन्माद्यस्य यत इति भगवता जन्मादिकर्तृत्वं भगवत उक्तं । सृष्टिरक्षाहातिज्ञान नियत्यज्ञानबन्धनात् । मोक्षं च विष्णुतश्चैव ज्ञात्वा मुक्तिर्नचान्यथेति" भगवत्पादैस्तद्ज्ञानाभावे मोक्षाभाव उक्तः। अतस्तत्प्रकारो लेशेन प्रपञ्च्यते ।

आसीदुदारगुणवारिधिरप्रमेयो
नारायणः परतरः परमात्म एकः ।
संशान्तसंविदखिलं जठरे निधाय
लक्ष्मीभुजान्तरगतः स्वरतोऽपि चाग्रे ॥
तस्योदरस्थजगतः सदमन्दसान्द्र-
स्वानन्द तुष्टवपुरुषोपि रमारमस्य ।
भूत्यै निजाश्रित जनस्य हि सृज्यसृष्टा-
वीक्षा बभूव परनाप निमेषकान्ते ॥

अत्र सृज्य सृष्टावित्यस्य पराधीनविशेषाप्त्या जनिमत्सर्वमेवचेति यत्पराधीन विशेषावाप्तिमत्वं सृज्यतावछेदकमुक्तम् । तदवछिन्न सर्वसृष्टा-वित्यर्थः ।

End :

एवं विदुर्ये परमामनन्ता
मजस्य शक्तिं पुरुषोत्तमस्य ।
तस्य प्रसादादथ दग्धदोषाः
तमाप्नुवन्त्याशु परं परेशम् ॥
देवानिमान् मुक्तसमस्तदोषान्
स्वसन्निधाने विनिवेश्य देवः ।
पुनस्तदन्या नधिकारयोग्यां-
स्तत्तद्गुणानेव पदे प्रयुङ्क्ते ॥ इत्यशेषमतिमङ्गलम् ।

कवेरजोत्तुङ्गतरङ्गसङ्गते-
रङ्गे शयाने भुजगेन्द्रभोगे ।
श्रीरङ्गनायकयुग्मगूहिताङ्गे
मुक्तावलीं मे गुरवोऽर्पयन्तु ॥
श्रीविठलार्यपुत्रेण श्रीमत्तीर्थार्यसेविना ।
कृतेयं श्रीनिवासेन सृष्टिमुक्तावली शुभा ।

Colophon :

इति श्रीश्रीनिवासार्यविरचिता सृष्टिमुक्तावली समाप्ता ॥

R. No. 5815

Paper. 8¼ × 5¼ inches. Foll. 12. Lines, 13 on a page. Devanāgarī. Good. Extent, 240 Granthas.

Purchased in 1936–37 from Śrī Veṅkaṭaramaṇācar, Hanumantalāla Street, Triplicane, Madras.

ब्रह्मसूत्राणुभाष्यटीका
BRAHMASŪTRĀṆUBHĀṢYAṬĪKĀ.

Similar to the work described under R. No. 4106 *ante*.

Complete.

Beginning :

लक्ष्मीनारायणं नत्वा व्यासं मध्वादिकान् गुरून् ।
ब्रह्मसूत्राणुभाष्यस्य तात्पर्यं संप्रकाश्यते ॥

भगवानाचार्यवर्यः ब्रह्मसूत्राणि भाष्यादिभिः सम्य ग्व्याख्यायाल्पाधिकारिणामनुदिनपठनार्थमधिकरणसंग्रहव्याजेन सर्वशास्त्रार्थसंग्रहरूपमणुभाष्यं कर्तुकामः क्रमेणाध्यायचतुष्टयप्रतिपाद्यविशे(ष)ण विशिष्टतया गुरुत्वेन च श्रीनारायणं प्रणमन् चिकीर्षितं प्रतिजानीते । —नारायणमिति । गुरून् व्यासान् । अपिपदेन स्वस्य गुरूदेवताभेदे रुचिं सूचयति । अनेनैव प्रेक्षावत्प्रवृत्त्यङ्गं विषयादिकं सूचितं । नारायण एव विषयः । तद् ज्ञानयोग्यः तदिच्छुरेवाधिकारी । ज्ञानगमने प्रयोजने यथायोग्यं सम्बन्धः ।

Colophon :

इति प्रथमाध्यायस्य लोकतोऽन्यत्र प्रसिद्धनामात्मकः पादः समाप्तः ।

End :

अध्यायचतुष्टयप्रतिपाद्यत्वेनान्तेपि मङ्गलमाचरितं

प्रत्यध्यायं प्रतिनयं प्रतिपादं च वर्णशः ।

वासुदेवादिरूपेण प्रोक्तो विष्णुः प्रसीदताम् ॥

Colophon :

इत्यणभाष्यटीका समाप्ता ।

Scribe adds :

इन्द्रियाणि दशैकं च मनस्तन्मात्रकास्तथा

पञ्चैव षोडशकलं लिङ्गदेहमनादितः ।

R. No. 5816

Paper. 6¼ × 4¼ inches. Foll. 15. Lines, 9 on a page. Devanāgarī. Good. Extent, 180 Granthas.

Purchased in 1936–37 from Śrī Veṅkaṭaramaṇācār, Hanumantalālā Street, Triplicane, Madras.

द्वादशस्तोत्रम्—आनन्दतीर्थप्रणीतम्

DVĀDAŚASTOTRAM by Ānandatīrtha.

Same work as that described under D. No. 10068.

Complete.

R. No. 5817

Paper. 8¼ × 4¼ inches. Fol. 51. Lines, 9 on a page. Devanāgarī. Good. Extent, 816 Granthas.

Purchased in 1936–37 from Śrī Veṅkaṭaramaṇācār, Hanumantalālā Street, Triplicane, Madras.

भगवद्गीता by व्यासरचिता

BHAGAVADGĪTĀ by Vyāsa.

Same work as described under D. No. 1992.

Complete.

R. No. 5818

Paper. 8 × 4 inches. Foll. 251. Lines, 10 on a page. Devanāgarī. Good. Extent, 4,016 Granthas.

Purchased in 1936–37 from Śrī Veṅkaṭaramaṇācār, Hanumantalālā Street, Triplicane, Madras.

भागवततात्पर्यनिर्णयः—आनन्दतीर्थप्रणीतः

BHĀGAVATATĀTPARYANIRṆAYAḤ by Ānandatīrtha.

Same work as that described under D. No. 4823.

Complete.

R. No. 5819

Paper. 4¾ × 3 inches. Foll. 42. Lines, 6 on a page. Devanāgarī. Good. Extent, 261 Granthas.

Purchased in 1936-37 from Śrī Veṅkataramaṇācār, Hanumantalālā Street, Triplicane, Madras.

कृष्णामृतमहार्णवः—आनन्दतीर्थप्रणीतः

KṚṢṆĀMṚTAMAHĀRṆAVAḤ by Ānandatīrtha.

Same work as that described under R. No. 1448.

Complete.

R. No. 5820

Paper. 7¾ × 3¾ inches. Foll. 57. Lines, 8 on a page. Devanāgarī. Good. Extent, 400 Granthas.

Purchased in 1936-37 from Śrī Veṅkaṭaramaṇācar, Hanumantalālā Street, Triplicane, Madras.

भगवद्गीता—व्यासरचिता

BHAGAVADGĪTĀ by Vyāsa.

Same work as that described under D. No. 1992.

Wants some portion of 1-7 and 8 Adhyāyas : Otherwise complete.

R. No. 5821

Paper. 8¼ × 4¼ inches. Foll. 11. Lines, 12 on a page. Devanāgarī. Not good. Extent, 100 Granthas. Printed.

Purchased in 1936-37 from Śrī P. Veṅkaṭaramaṇācār, 22, Raja Hanumantalālā Street, Triplicane, Madras.

भेदोज्जीवनम् by व्यासतीर्थः ।

BHEDOJJĪVANAM by Vyāsatīrtha.

Same work as that described under D. No. 17092.

Wants the end.

R. No. 5822

Paper. 8¼ × 4¼ inches. Foll. 13. Lines, 12 on a page. Devanāgarī. Not good. Extent, 120 Granthas. Printed.

Purchased in 1936-37 from Śrī P. Veṅkaṭaramaṇācār, 22, Raja Hanumantalālā Street, Triplicane, Madras.

भेदोज्जीवनटिप्पणी

BHEDOJJĪVANAṬIPPAṆĪ.

Similar to the work described under R. No. 454.

Wants the end.

R. No. 5823

Paper. 10¼ × 4¼ inches. Foll. 17. Lines, 9 on a page. Devanāgari. Good. Extent, 180 Granthas. Printed.

Purchased in 1936-37 from Śrī P. Veṅkaṭaramaṇācār 22, Raja Hanumantalālā Street, Triplicane, Madras.

तत्त्वविवेकटीकाव्याख्या—भावप्रकाशिका by व्यासयतिः

TATTVAVIVEKAṬĪKĀVYĀKHYĀ—BHĀVAPRAKĀŚIKĀ by Vyāsa-yati.

Same work as that described under R. No. 1323 (c).

Complete.

R. No. 5824

Paper. 8 × 4¼ inches. Foll. 26. Lines, 12 on a page. Nandināgarī. Injured. Extent, 566 Granthas. Printed.

Purchased in 1936-37 from Śrī P. Veṅkaṭaramaṇācār, 22, Raja Hanumantalālā Street, Triplicane, Madras.

तत्त्वविवेकव्याख्यानविवरणम् by श्रीनिवासः ।

TATTVAVIVEKAVYĀKHYĀNAVIVARAṆAM by Śrīnivāsa.

A commentary on Jayatīrtha's Tattvavivekavyākhyā, which work has been described under D. No. 4786.

Beginning :

आनन्दादिगुणोद्रिक्तस्वाश्रितानन्ददायकम् ।
आनन्दात्मकसन्देहं भजेह बादरायणम् ॥
श्रीमदानन्दतीर्थार्यान् जयराजमुनीनपि ।
वेदेशाख्य मुनीन् वन्दे गुरूणामपि सद्गुरून् ॥
प्रणम्य यादवाचार्यगुरूणां पादपङ्कजे ।
टीकां तत्त्वविवेकस्य व्याकुर्वे तत्कृपाबलात् ॥

इहहि परमकारुणिको जयतीर्थ श्रीमच्चरणः तत्त्वविवेकव्याख्यां कर्तुकामः प्रारिप्सितपरिसमाप्त्यादिप्रयोजनतया शिष्टाचारपरम्परावगतं रमापतिप्रणतिं आदिगुरूणां परमगुरूणां प्रणतिश्चविधाय शिष्याशिक्षायै ग्रन्थादौ तामुपनिबन्धन् श्रोतृबुध्यनुकूलनाय स्वचिकीर्षितं प्रतिजानीते । प्रणम्येति । ल्यपा नमस्कारस्य ग्रन्थकरणात्पूर्वत्वकथनात्तयो रङ्गाङ्गिभावः सूचितो ज्ञातव्यः ।

End :

अभिवादनं करोमि । स्तौमिचेत्यर्थः । कमला श्रीर्हरिप्रियेत्यभिधानात् कमला महालक्ष्मीरित्यशेषमतिमङ्गलम् ।

यादवाचार्यहृत्पद्मगत श्रीमध्ववल्लभः ।
प्रीयतामनया ग्रन्थकृत्या श्रीबादरायणः ॥
लौकिकालौकिकफल लक्षणामृतदोहिनीम् ।
गुर्वनुग्रहरूपां तां कामधेनुमुपास्महे ॥

Colophon :

इति श्रीमद्यदुपत्याचार्यपूज्यपादाराधकेन श्रीनिवासेन विरचितं तत्त्वविवेकव्याख्यानविवरणं समाप्तम् ।

R. No. 5825

Paper. $6\frac{1}{4} \times 4\frac{1}{2}$ inches. Foll. 27. Lines, 7 on a page. Devanāgarī. Injured. Extent, 162 Granthas. Printed.

Purchased in 1936–37 from Śrī P. Veṅkaṭaramaṇācār, 22, Raja Hanumantalālā Street, Triplicane, Madras.

द्वादशस्तोत्रम् by आनन्दतीर्थः

DVĀDAŚASTOTRAM by Ānandatīrtha.

Same work as that described under D. No. 10068.

Foll. 27th is left blank.

R. No. 5826

Paper. 8×5 inches. Foll. 130. Lines, 15 on a page. Devanāgarī. Slightly injured. Extent, 4,060 Granthas. Not printed.

Purchased in 1936–37 from Śrī P. Veṅkaṭaramaṇācār, 22, Raja Hanumantalālā Street, Triplicane, Madras.

भगवद्गीतार्थप्रकाशः

BHAGAVADGĪTĀRTHAPRAKĀŚAH.

This work elucidates the idea contained in the Bhagavadgītā.

Complete.

Beginning :

क्षत्रियाणां विशेषतो नारायणाद्विट्तदनुबन्धिनिग्रहं परमधर्मं बन्धुस्नेहादिना अधर्मत्वेनाशङ्क्य ततो निवृत्तप्रायमात्मनः प्रियतम मर्जुनं निमित्तीकृत्य स्वविहितवृत्त्या भक्त्या भगवदाराधनमेव परमधर्मः तद्विरुद्धः सर्वोऽप्यधर्मः तदधीनत्वात्सर्वस्येतिभावेन सकलसज्जनान् बोधयति भगवन्नारायण इत्याह—भगवानुवाचेति । तत्रादावर्जुनेन दृष्ट्वेमं स्वजनंकृष्णेत्यादिना यः शोकः कृतः यच्च पापमेवाश्रयेदस्मानित्यादिना मोक्षशास्त्रविरुद्धं वचनमुक्तं तदुभयमयुक्त मित्याह— अशोच्यानिति ।

Colophon :

इति श्रीमद्भगवद्गीतार्थप्रकाशे द्वितीयोऽध्यायः ।

End :

एवं सर्वार्थान् सम्यगवजानतः । तवसमुपेतसेनाद्वये जयापजयविवेकः कथं भासयत इत्यत आह । यत्रेति । यत्र यस्मिन् पक्षे योगेश्वरः सर्वोपयाना मीश्वरः उत्तरोत्तराभिवर्धैश्वर्यततः सर्वतो विजयः ततश्चश्री; महासाम्राज्यलक्ष्मीरिति ।

Colophon :

इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे परमार्थनिर्णययोगो नामाष्टादशोऽध्यायः ।

Scribe adds :

इदं पुस्तकं लक्ष्मणसुतकृष्णेन लिखितम् । शके । १८०६ तारणवत्सर फाल्गुनमासे १२ गुरुवारे तिण्डिवनग्रामे लिखितम् ।

R. No. 5827

Paper. 9 × 3¾ inches. Fol. 29. Lines, 12 on a page. Devanāgarī. Injured. Extent, 672 Granthas. Printed.

Purchased in 1936–37 from Śrī P. Veṅkaṭaramaṇācār, 22, Raja Hanumantalālā Street, Triplicane, Madras.

वादावलिः by जयतीर्थः ।

VĀDĀVALIḤ by Jayatīrtha.

Same work as that described under D. No. 4983.
Wherein see for the beginning.
Complete.

End :

परस्परसुखदुःखाद्यनुसन्धानप्रसङ्गपराहतं च विमतानि कलत्राणि देवदत्तस्यैव भोगायतनानि कलत्रत्वात् संप्रतिपन्नकलत्रवदित्याद्याभाससमान योगक्षेमतयापहास्यं ।

जयतीर्थमुनीन्द्रेण मुग्धबोधाय निर्मितम् ।
वाङ्मुखाद्वाङ्मुखं भूयात् प्रीतये हरिमध्वयोः ॥

Colophon :

इति श्रीमज्जयतीर्थभिक्षुविरचिता वादावलिः समाप्ता ।

R. No. 5828

Paper. 9 × 4½ inches. Foll. 42. Lines, 8 on a page. Devanāgarī. Injured. Extent, 533 Granthas. Printed.

Purchased in 1936–37 from the Śrī P. Veṅkaṭaramaṇācār, 22, Raja Hanumantalālā Street, Triplicane, Madras.

ईशावास्योपनिषद्भाष्यटीका by जयतीर्थः

ĪŚĀVĀSYOPANIṢADBHĀṢYAṬĪKĀ by Jayatīrtha.

Same work as that described under R. No. 493.

Complete.

R. No. 5829

Paper. 12 × 5¼ inches. Foll. 128. Lines, 11 on a page. Devanāgarī. Injured. Extent, 3,520 Granthas. Printed.

Purchased in 1936–37 from Śrī P. Veṅkaṭaramaṇācār, 22, Raja Hanumantalālā Street, Triplicane, Madras.

शेषधर्मः

ŚEṢADHARMAḤ.

Same work as that described under D. No. 2087.

Contains 1 to 57 Adhyāyas.

R. No. 5830

Paper. 12½ × 6 inches. Foll. 122. Lines, 10 on a page. Devanāgarī. Slightly injured. Extent, 3,418 Granthas. Printed.

Purchased in 1936–37 from Śrī P. Veṅkaṭaramaṇācār, 22, Raja Hanumantalālā Street, Triplicane, Madras.

भगवद्गीता—श्रीधरकृतसुबोधिनीव्याख्यासहिता

BHAGAVADGĪTĀ with VYĀKHYĀ SUBODHINĪ of Śrīdhara.

Same work as that described under D. No. 2064.

R. No. 5831

Paper. 12¾ × 5¼ inches. Foll. 30. Lines, 15 on a page. Devanāgarī. Slightly injured. Extent, 2,100 Granthas. Not printed.

Purchased in 1936-37 from Śrī P. Veṅkaṭaramaṇācār, 22, Raja Hanumantalālā Street, Triplicane, Madras.

अभिनवताण्डवः by सत्यनाथतीर्थः ।

ABHINAVATĀṆḌAVAḤ by Satyanāthatīrtha.

Same work as that described under R. No. 5807.

Anumānakhaṇḍa complete.

R. No. 5832

Paper. 11½ × 4¾ inches. Foll. 50. Lines, 12 on a page. Devanāgarī. Injured. Extent, 1,500 Granthas. Printed.

Purchased in 1936-37 from Śrī P. Veṅkaṭaramaṇācār, 22, Raja Hanumantalālā Street, Triplicane, Madras.

भगवद्गीताभाष्यम् by आनन्दतीर्थः ।

BHAGAVADGĪTĀBHĀṢYAM by Ānandatīrtha.

Same work as that described under D. No. 2080.

Complete.

R. No. 5833.

Paper. 12¾ × 4½ inches. Foll. 18. Lines, 8 on a page. Devanāgarī. Injured. Extent, 924 Granthas. Printed.

Purchased in 1936-37 from Śrī P. Veṅkaṭaramaṇācār, 22, Raja Hanumantalālā Street, Triplicane, Madras.

प्रपञ्चमिथ्यात्वानुमानखण्डनव्याख्या—पञ्चिका by जयतीर्थः ।

PRAPAÑCAMITHYĀTVĀNUMĀNAKHAṆḌANAVYĀKHYĀ PAÑCIKĀ by Jayatīrtha.

Same work as that described under D. No. 4800.

Complete.

R. No. 5834

Paper. 12¼ × 4¼ inches. Foll. 9. Lines, 8 on a page. Devanāgarī. Injured. Extent, 162 Granthas. Printed.

Purchased in 1936-37 from Śrī P. Veṅkaṭaramaṇācār, 22, Rāja Hanumantalālā Street, Triplicane, Madras.

मायावादखण्डनव्याख्या by जयतीर्थः

MĀYĀVĀDAKHAṆḌANAVYĀKHYĀ by Jayatīrtha.

Same work as that described under D. No. 4836.

Complete.

R. No. 5835

Paper. 12¼ × 4¼ inches. Foll. 9. Lines, 9 on a page. Devanāgarī. Injured. Extent, 172 Granthas. Printed.

Purchased in 1936-37 from Śrī P. Veṅkaṭaramaṇācār, 22, Raja Hanumantalālā Street, Triplicane, Madras.

तत्त्वविवेकव्याख्या by जयतीर्थः ।

TATTVAVIVEKAVYĀKHYĀ by Jayatīrtha.

Same work as that described under D. No. 4786.

Complete.

R. No. 5836

Paper. 12 × 4¼ inches. Foll. 31. Lines, 9 on a page. Devanāgarī. Injured. Extent, 686 Granthas. Printed.

Purchased in 1936-37 from Śrī P. Veṅkaṭaramaṇācār, 22, Raja Hanumantalālā Street, Triplicane, Madras.

प्रमाणलक्षणटीका—न्यायकल्पलता by जयतीर्थः

PRAMĀṆALAKṢAṆAṬĪKĀ—NYĀYAKALPALATĀ by Jayatīrtha.

Same work as that described under D. No. 4808.

Wants the end; otherwise complete.

R. No. 5837

Paper. 12¼ × 4¼ inches. Foll. 9. Lines, 9 on a page. Devanāgarī. Injured. Extent, 96 Granthas. Printed.

Purchased in 1936-37 from Śrī P. Veṅkaṭaramaṇācār, 22, Raja Hanumantalālā Street, Triplicane, Madras.

तत्त्वसंख्यानविवरणम् by जयतीर्थः ।

TATTVASAṄKHYĀNAVIVARAṆAM by Jayatīrtha.

Same work as that described under D. No. 4789.

R. No. 5838

Paper. 8¼ × 4¼ inches. Foll. 7. Lines, 11-13 on a page. Devanāgari. Injured. Extent, 85 Granthas. Not printed.

Purchased in 1936-37 from Śrī P. Veṅkaṭaramaṇācār, 22, Raja Hanumantalālā Street, Triplicane, Madras.

मन्त्रपद्धतिः

MANTRAPADDHATIḤ.

Similar to the work described under R. No. 3617 (c).

Complete.

Beginning :

तत्त्वन्यासमातृकान्यासानन्तरं संध्यागायत्रीजपः कार्यः । अथाष्टाक्षरमन्त्रः । गुरुनमस्कारः ओं ओं नमो नारायणाय । ओमिति मन्त्रेण प्राणायामः । ३६, २४, १२,—अथाष्टाक्षरन्यासः । ओं ओं विश्वाय नमः । शिरसि । ओं नं तैजसाय नमः । नेत्रयोः । ओं मों प्राज्ञाय नमः । नासिकायां । ओं नां तुर्याय नमः । वदने । ओं रां आत्मने नमः हृदये । ओं यं अन्तरात्मने नमः । पादयोः । अथा ष्टाङ्गुलिन्यासः ।

. . . .

. . . .

इति नारायणाष्टाक्षरमन्त्रः । अथप्रणवमन्त्रः । गृहस्थैर्मूलमन्त्रानन्तरं जप्यः । गुरुनमस्कारः । एकादशस्थाने नारायणाय नमः । ओं ओं ओं इति मन्त्रेण प्राणायामः ।

End :

अस्य हंसमहामन्त्रस्य ब्रह्मा ऋषिः । गायत्री छन्दः । हंसरूपी नारायणो देवता । ध्याने विनियोगः ।

ध्यायेद्रवीन्दुकरमिन्दुसहस्रलक्ष
कान्तिमया सहितमास्ति बिम्बे ।
शङ्खारिदोर्द्वयमुदर्क महेन्दुबिम्बं
संसिच्यमानममृतेन रमादिनाथम् ॥
हंसरूपी नारायणप्रेरणया नारायण-
प्रीत्यर्थं हंसमन्त्रजपं करिष्ये । मन्त्रः ।

हंसः सोहं स्वाहा—जपसंङ्ख्या पूर्ववत् । जपसमाप्तिप्रकारस्तु प्रातः फलपूर्वत्युक्तः ।

R. No. 5839

Paper. 12 × 4½ inches. Foll. 11. Lines, 10 on a page. Devanāgarī. Injured. Extent, 120 Granthas. Printed.

Purchased in 1936-37 from Śrī P. Veṅkaṭaramaṇācār, 22, Hanumantalālā Street, Triplicane, Madras.

नरसिंहस्तुतिः—सव्याख्या by त्रिविक्रम and नारायणाचार्य

NARASIMHASTUTIH with vyākhyā by Trivikramācārya and Nārāyaṇa.

Same work as that described under D. No. 10077.

Complete.

Colophon :

इति श्रीमद्विद्वन्मुकुटाविश्वनाथसूरिनारायणपण्डिताचार्यविरचिता श्रीमत् परमाब्धिपरिचैरैकनिमानमहाकविकोटिसंघट्टितपादपीठ श्रीमत्त्रिविक्रम पण्डिताचार्यविरचिता श्रीमन्नृसिंहस्तुतिव्याख्यानं संपूर्णम् ।

R. No. 5840

Paper. 9¼ × 4½ inches. Foll. 27. Lines, 10 on a page. Devanāgarī. Injured. Extent, 200 Granthas. Printed.

Purchased in 1936-37 from Śrī P. Veṅkataramaṇācār, 22, Hanumantalālā Street, Triplicane, Madras.

स्वाप्नबृन्दावनम् by वादिराजः

SVĀPNABṚNDĀVANAM by Vādirāja.

Same work as that described under D. No. 15265.

Contains 4 to 9 Adhyāyas in Prathamaprāṇaparicchedа of Alaukikavibhāga. Incomplete.

R. No. 5841

Paper. 10½ × 4½ inches. Foll. 8. Lines, 9 on a page. Devanāgarī. Injured. Extent, 64 Granthas. Printed.

Purchased in 1936-37 from Śrī P. Veṅkataramaṇācār, Hanumantalālā Street, Triplicane, Madras.

प्रपञ्चमिथ्यात्वानुमानखण्डनव्याख्या ।

PRAPAÑCAMITHYĀTVĀNUMĀNAKHAṆḌANAVYĀKHYĀ.

Similar to the work described under D. No. 4800.

Complete.

Beginning :

भगवता बादरायणेन जन्माद्यस्य यत इति ब्रह्ममीमांसाशास्त्रे जगदुदयादि निमित्तकारणत्वं परब्रह्मणोलक्षणो लक्षणमभिहितं । तत्राहुरद्वैतवादिनः । जगतोमिथ्यात्वेन जगदुदयादिनिमित्तकारणात्वस्यापि मिथ्यात्वात् लक्षणसूत्रमयुक्तम् । जगन्मिथ्यात्वे प्रमाणाभाव इति वाच्यं । अनुमानरूपप्रमाणस्यैव विद्यमानत्वात् । तथाहि—विमतं मिथ्या - दृश्यत्वात् ।

End :

तस्मात् साध्यविकलः स्यादेव । किंचैतावन्तं कालं अहं शुक्तिकामेव रजतत्वेन प्रतिपन्नोस्मीत्युत्तरकाले परामर्शस्य जायमानत्वेन तत्रदृश्यत्वाभावात् साधनविकलो दृष्टान्तः । किंच विमतं मिथ्या दृश्यत्वादित्यनुमाने प्रमाणविरुद्धस्वरूपोपाधे विद्यमानत्वेनोपाधिग्रस्तानुमानस्य साध्यसाधनव्याप्त्यभावात् दृश्यत्वानुमानेन प्रपञ्चस्य मिथ्यात्वसाधनमयुक्तमेतत् ।

Colophon :

इति प्रपञ्चमिथ्यात्वानुमानखण्डनं समाप्तम् ।

R. No. 5842

Paper. 12 × 4½ inches. Foll. 13. Lines, 8 on a page. Devanāgarī. Injured. Extent, 150 Granthas. Printed.

Purchased in 1936–37 from Śrī P. Veṅkaṭaramaṇācār, Hanumantalālā Street, Triplicane, Madras.

उपाधिखण्डनटीका by जयतीर्थ

UPĀDHIKAṆḌANAṬĪKĀ by Jayatīrtha.

Same work as that described under D. No. 4782.

Complete.

R. No. 5843

Paper. 11¾ × 4 inches. Foll. 15. Lines, 8 on a page. Devanāgarī. Injured. Extent, 200 Granthas. Printed.

Purchased in 1936–37 from Śrī P. Veṅkaṭaramaṇācār, Hanumantalālā Street, Triplicane, Madras.

ब्रह्मसूत्रानुव्याख्यानम् by आनन्दतीर्थः
BRAHMASŪTRĀNUVYĀKHYĀNAM by Ānandatīrtha.

Same work as that described under R. No. 452.

Contains 1st Pāda only.

R. No. 5844

Paper. 6½ × 4½ inches. Foll. 179. Lines, 9 on a page. Devanāgarī. Injured. Extent, 3,580 Granthas. Printed.

Purchased in 1936–37 from Śrī P. Veṅkaṭaramaṇācār, Hanumantalālā Street, Triplicane, Madras.

ब्रह्मसूत्रभाष्यम् by आनन्दतीर्थः
BRAHMASŪTRABHĀṢYAM by Ānandatīrtha.

Same work as that described under R. No. 477.

Wants the beginning and end, 1, 2, 20, 33 to 36, 119, 120, 159, 160, 165, 166, 183 and 191 leaves are left blank.

R. No. 5845

Paper. 9 × 4½ inches. Foll. 123. Lines, 11 on a page. Devanāgarī. Injured. Extent, 2,900 Granthas. Not printed.

Purchased in 1936–37 from Śrī P. Veṅkaṭaramaṇācār, Hanumantalālā Street, Triplicane, Madras.

तत्वोद्योतविवरणव्याख्या by केशव.
TATTVODYOTAVIVARAṆAVYĀKHYĀ by Keśava.

A commentary on Jayatīrtha's Tattvodyotavivaraṇa, which work has been described under D. No. 4792.

Complete.

Beginning :

यद्विद्याधीशगुरोः शुश्रूषान्या नरोचते तस्मात् ।
अस्त्वेषामक्तियुता श्रीविद्याधीशपादयोः सेवा ॥
तत्वोद्योतस्य विवृतेर्विद्याधीशोक्त . . . तिः ।
विवृतिर्भावगूढायाः क्रियते मन्दबुद्धये ॥
स्पष्टार्थं यत्पदं वाक्यं तन्न व्याक्रियतेमया ।
ग्रन्थगौरवभीरुत्वान्नचोद्ग्रन्थं बहूच्यते ।

ग्रन्थादौ मङ्गलमाचरन्नेव शिष्यावधानार्थं चिकीर्षितं निर्दिशति। विश्वेति। नन्विन्द्राग्नीत्यत्र तत्र तत्र सावकाशाद्यन्ताद्यतशास्त्रयो रुभयोरपि प्रसङ्गेपि विप्रतिषेधे परमिति न्यायेन परत्वादजाद्यतशास्त्रस्यैव प्रवृत्येन्द्रशब्दस्यैव पूर्वनिपातवत् अजाद्यदन्तमित्यस्येशकृष्णावित्यत्राल्पाच् तरमित्यस्य च प्लक्षन्यग्रोधावित्यत्र सावकाशत्वेनोत्पत्तिस्थितीत्यत्र तदुभयप्रसङ्गे विप्रतिषेधेपरमिति न्यायेन परत्वात् अल्पाच् तरशास्त्रस्यैव प्रवृत्त्या स्थिति-शब्दस्यैव पूर्वनिपातः स्यादितिचेद् अत्र स्वामिनः।

End:

तयोराश्रय इति बहुव्रीहिरर्थस्य बाधितत्वात् वर्तिपदार्थप्रधानत्वेन समासप्राबल्याच्चेति समापितग्रन्थव्याख्यानटीकाकारः गुर्वन्तर्गतभगवत्प्रीति-माशास्ते श्रीमदिति। कमलेत्यनेन भगवत्प्रीतिः प्रार्थिता भवतीत्यशेष मतिमङ्गलम्।

यद्विद्याधीशगुरोःशुश्रूषान्या नरोचते तस्मात्।
अस्त्वेषाभक्तियुता श्रीविद्याधीशपादयोः सेवा॥

Colophon:

इति श्रीमत्सकलविद्वच्चक्रचूडामणिपदवाक्यप्रमाणविदामग्रेसराणां श्रीम-द्विद्याधीशपूज्यपादानां निजशिष्येण केशवेन कृतं तत्वोद्योतविषमविवरणं समाप्तम्।

R. No. 5846

Paper. 8 × 4½ inches. Foll. 42. Lines, 10 on a page. Devanāgarī. Good. Extent, 500 Granthas. Printed.

Purchased in 1936–37 from Śrī P. Veṅkaṭaramaṇācār, Hanumantalālā Street, Triplicane, Madras.

उपाधिखण्डनटीकाव्याख्या by श्रीनिवासः

UPĀDHIKHAṆḌANAṬĪKĀVYĀKHYĀ by Śrīnivāsa.

Similar to the work described under R. No. 3928 (*l*).

Complete.

Beginning :

पूर्णबोधकरसेवितपादं सज्जनेष्टदमनन्तसद्गुणम् ।
वासवीहृदयनन्दनं हरिं बादरायणमहं भजेऽनिशम् ।
भाविब्रह्मतयाम्नातानन्दतीर्थानहं मुहुः ।
जयराजमुनींश्चापि वन्दे वेदेशयोगिनः ।
प्रणम्य यादवाचार्यगुरूणां पादपङ्कजे ।
उपाधिखण्डनव्याख्यां व्याकुर्वे तत्कृपाबलात् ।

सर्वज्ञकल्पाष्टीकाकारा जयतीर्थश्रीमच्चरणाः तत्त्वप्रकाशिकापर-पर्यायस्योपाधिखण्डनस्य व्याख्यां कर्तुकामाः स्वचिकीर्षितस्य ग्रन्थस्य निर्विघ्नेन परिसमाप्त्यर्थं स्वेष्टदेवतानमस्कारमङ्गलं मनसिकृत्वा शिष्यशि-क्षायै ग्रन्थादा वुपनिबध्नन्तः सन्तः स्वचिकीर्षितं प्रतिजानते । रमाया रमणमिति ।

End :

त्विष् कान्तौ । सुरशिरोरत्नप्रभामोषिणी नखत्विट् यस्य तत् सुरशिरो-रत्नप्रभामोषिनखत्विट् तस्मिन् सुरशिरोरत्नप्रभानखत्विषि । त्विट् त्विषी त्विषीति षकारान्तनपुंसकलिङ्गत्विषुशब्दस्येयं सप्तमीतिज्ञातव्यं । राति रासाक्तिर्भक्तिरिति यावत् । सदास्त्वित्य शेषमतिमङ्गलम् ।

यादवाचार्यहृत्पद्मगतश्रीमध्वहृद्गतः ।
प्रीयतामनयाग्रन्थकृत्या व्यासो दयानिधिः ॥

Colophon :

इति श्रीयदुपत्याचार्यपूज्यपादाराधकेन श्रीनिवासेन विरचिततत्त्व प्रकाशिकापरपर्यायोपाधिखण्डनव्याख्याविवृतिः समाप्ता ।

Scribe adds :

शके १७७७ राक्षसनामसंवत्सरे चैत्रकृष्णप्रतिपद्यां(दि)समाप्तं ।

R. No. 5847

Paper. 8¼ × 6¼ inches. Foll. 202. Lines, 16 on a page. Nandinâgari. Injured. Extent, 5,050 Granthas. Printed.

Purchased in 1936–37 from Śrî P. Veṅkaṭaramaṇâcâr, Hanumantalâlâ Street, Triplicane, Madras.

ब्रह्मसूत्रानुव्याख्यानटीका—न्यायसुधा—by जयतीर्थ

BRAHMASŪTRĀNUVYĀKHYĀNAṬĪKĀ—NYĀYASUDHĀ by Jayatīrtha.

Same work as that described under R. No. 876.

Contains 1st and 2nd Padās of 2nd Adhyāya. Incomplete.

R. No. 5848

Paper. 8½ × 3 inches. Foll. 79. Lines, 6 on a page. Devanāgarī. Good. Extent, 800 Granthas. Printed.

Purchased in 1936-37 from Śrī P. Veṅkaṭaramaṇācār, Hanumantalālā Street, Triplicane, Madras.

भगवद्गीता—व्यासरचिता

BHAGAVADGĪTĀ by Vyāsa.

Same work as that described under D. No. 1992.
Complete.

R. No. 5849

Paper. 10½ × 3 inches. Foll. 74. Lines, 7 on a page. Devanāgarī. Injured. Extent, 800 Granthas. Printed.

Purchased in 1936-37 from Śrī P. Veṅkaṭaramaṇācār, Hanumantalālā Street, Triplicane, Madras.

भगवद्गीताभाष्यम् by आनन्दतीर्थ

BHAGAVADGĪTĀBHĀṢYAM by Ānandatīrtha.

Same work as that described under D. No. 2080.
Complete.

R. No. 5850

Paper. 9 × 4½ inches. Foll. 25. Lines, 9 on a page. Devanāgarī. Injured. Extent, 280 Granthas. Printed.

Purchased in 1936-37 from Śrī Veṅkaṭaramaṇācār, Triplicane Madras.

तन्त्रसारसंग्रहः by आनन्दतीर्थ

TANTRASĀRASAṄGRAHAḤ by Ānandatīrtha.

Complete.

Same work as that described under No. 573 (*l*).

R. No. 5851

Paper. 10 × 5 inches. Foll. 34. Lines, 14 on a page. Dēvanāgarī. Slightly injured. Extent, 1,200 Granthas.

Purchased in 1936-37 from Śrī Veṅkaṭaramaṇācārya, Triplicane, Madras.

रुक्मिणीशविजयः सव्याख्यः

RUKMIṆĪŚAVIJAYAḤ

With commentary by Vādirāja and Nārāyaṇa Bhaṭṭa

Contains Sargas 1 to 13 complete.

Same work as that described under D. No. 11718 where in see for end.

Beginning :

हत्वा पूतनिकां विभज्य शकटं जित्वार्जुनौ दानवौ
(अघ्या) रुह्य विनाश्य कालियविषं निष्पीऽयरिष्टवरम् ।
भित्वा केशिन मुन्मदं विषतरुं चोद्धृत्य गोवर्धनं
यः कंसं सगजेन्द्रमल्ल मवधी त्तस्मै नमो विष्णवे ॥
योविद्याधिपति विंद्यामगाद्विश्वगुरुर्गुरोः ।
संपूर्णैश्वर्यसंपन्न स्तं शौरिं समुपास्महे ॥ तत इति ॥

R. No. 5852

Paper. 9½ × 4½ inches. Foll. 131. Lines, 12 on a page. Devanāgarī. Injured. Extent, 3,300 Granthas. Printed.

Purchased in 1936-37 from Śrī Veṅkaṭaramaṇācār, Triplicane, Madras.

विष्णुरहस्यम्

VIṢṆURAHASYAM.

Same work as that described under D. No. 2358.

Complete.

R. No. 5853

Paper. 8 × 4 inches. Foll. 59. Lines, 10 on a page. Devanāgarī. Injured. Extent, 1,750 Granthas. Printed.

Purchased in 1936-37 from Śrī Veṅkaṭaramaṇācār, Triplicane, Madras.

ऋग्भाष्यम्—आनन्दतीर्थप्रणीतम्

ṚGBHĀṢYAM by Ānandatīrtha.

Same work as that described under D. No. 31.

Complete.

R. No. 5854

Paper. 9½ × 5¼ inches. Foll. 76. Lines, 14 on a page. Devanāgarī. Injured. Extent, 1,500 Granthas. Printed.

Purchased in 1936-37 from Śrī Veṅkaṭaramaṇācār, Triplicane, Madras.

भागवतम्

BHĀGAVATAM.

Same work as that described under D. No. 2161.

Contains 48 adhyāyās in Daśamaskandha.

R. No. 5855

Paper. 9½ × 3½ inches. Foll. 150. Lines, 9 on a page. Devanāgarī. Injured. Extent, 3,750 Granthas. Printed.

Purchased in 1936-37 from Śrī Veṅkaṭaramaṇācār, Triplicane, Madras.

ब्रह्मसूत्रानुव्याख्यानटीका—न्यायसुधा by जयतीर्थ

BRAHMASŪTRĀNUVYĀKHYĀNAṬĪKĀ—NYĀYASUDHĀ by Jayatīrtha.

Same work as that described under D. No. 4820.

Contains jijñāsādhikaraṇa only incomplete.

R. No. 5856

Paper. 8 × 4 inches. Foll. 135. Lines, 9 on a page. Devanāgarī. Injured. Extent, 1,000 Granthas. Printed.

Purchased in 1936-37 from Śrī Veṅkaṭaramaṇācār, Triplicane, Madras.

ब्रह्मसूत्रभाष्यम् by आनन्दतीर्थ

BRAHMASŪTRABHĀṢYAM by Ānandatīrtha.

Same work as that described under D. No. 4810.

Complete.

R. No. 5857

Paper. 12 × 5¼ inches. Foll. 73. Lines, 10 on a page. Nandināgarī. Injured. Extent, 950 Granthas. Printed.

Purchased in 1936-37 from Śrī Veṅkaṭaramaṇācār, Triplicane, Madras.

ऋग्भाष्यटीका—जयतीर्थप्रणीता

RGBHĀṢYAṬĪKĀ by Jayatīrtha.

Same work as that described under D. No. 16909.

Complete.

R. No. 5858

Paper. 6 × 4 inches. Foll. 8. Lines, 12 on a page. Devanāgarī. Good. Extent, 150 Granthas.

Purchased in 1936–37 from Śrī Veṅkaṭaramaṇācārya, Triplicane, Madras.

तन्त्रसारसङ्ग्रहः by आनन्दतीर्थ

TANTRASĀRASAṄGRAHAḤ by Ānandatīrtha.

Same work as that described under R. No. 573 (*l*).

Incomplete.

R. No. 5859

Paper. $4\frac{1}{2} \times 2\frac{1}{2}$ inches. Foll. 4. Lines, 7 on a page. Devanāgarī. Injured. Extent, 50 Granthas. Printed.

Purchased in 1936–37 from Śrī Veṅkaṭaramaṇācār, Triplicane, Madras.

शिवस्तुतिः

ŚIVASTUTIḤ.

Same work as that described under R. No. 1431 (*f*).

Incomplete.

R. No. 5860

Paper. $7\frac{1}{2} \times 4$ inches. Foll. 13. Lines, 9 on a page. Devanāgarī. Good. Extent, 200 Granthas. Printed.

Purchased in 1936-37 from Śrī Veṅkaṭaramaṇācār, Triplicane, Madras.

तत्त्वसङ्ख्यानविवरणम् by जयतीर्थ

TATTVASAṄKYĀNAVIVARAṆAM by Jayatīrtha.

Same work as that described under D. No. 4789.

Wants beginning. Otherwise complete.

R. No. 5861

Paper. 5½ × 3 inches. Foll. 38. Lines, 5 in a page. Devanāgarī. Good. Extent, 400 Granthas. Printed.

Purchased in 1936-37 from Śrī Veṅkaṭaramaṇācār, Triplicane, Madras.

विष्णुसहस्रनामस्तोत्रम्

VIṢṆUSAHASRANĀMASTOTRAM.

Same work as that described under D. No. 9008.
Complete.

R. No. 5862

Paper. 4½ × 3 inches. Foll. 12. Lines, 6 on a page. Devanāgarī. Good. Extent, 95 Granthas. Printed.

Purchased in 1936-37 from Śrī Veṅkaṭaramaṇācār, Triplicane, Madras.

विष्णुस्तोत्रम् by नारायणपण्डित

VIṢṆUSTOTRAM. by Nārāyaṇapaṇḍita.

Same work as that described under D. No. 10357.
Contains 24 stanzas only.

R. No. 5863

Palm leaf. 7¾ × 2½ inches. Foll. 165. Lines, 11 on a page. Nandināgarī. Good.

Purchased in 1936-37 from Śrī P. Veṅkaṭaramaṇācar. Triplicane, Madras.

(a) ईशावास्योपनिषद्

ĪŚĀVĀSYOPANIṢAD.

Foll. 3a and 3b. Extent, 25 Granthas. Printed.
Same work as that described under D. No. 300.
Complete.

(b) ईशावास्योपनिषद्भाष्यम् by आनन्दतीर्थः

ĪŚĀVĀSYOPANIṢADBHĀṢYAM by Ānandatīrtha.

Foll. 3b—6b. Extent, 56 Granthas. Printed.
Same work as that described under D. No. 317.
Complete.

(c) प्रश्नोपनिषद्

PRAŚNOPANIṢAD.

Foll. 6b—11a. Extent, 120 Granthas. Printed.
Same work as that described under D. No. 610.
Complete.

(d) प्रश्नोपनिषद्भाष्यम् by आनन्दतीर्थः

PRAŚNOPANIṢADBHĀṢYAM by Ānandatīrtha.

Foll. 11a—13b. Extent, 50 Granthas. Printed.
Same work as that described under D. No. 622.
Complete.

(e) तलवकारोपनिषद्

TALAVAKĀROPANIṢAD.

Foll. 13b—15b. Extent, 60 Granthas. Printed.
Same work as that described under R. No. 573 (c).
Complete.

(f) तलवकारोपनिषद्भाष्यम् by आनन्दतीर्थः

TALAVAKĀROPANIṢADBHĀṢYAM by Ānandatīrtha.

Foll. 15b—18a. Extent, 66 Granthas. Printed.
Same work as that described under D. No. 393.
Complete.

(g) माण्डूक्योपनिषद्

MĀṆḌŪKYOPANIṢAD.

Foll. 18a—21a. Extent, 80 Granthas. Printed.
Same work as that described under D. No. 694.
Complete.

(h) माण्डूक्योपनिषद्भाष्यम् by आनन्दतीर्थः

MĀṆḌŪKYOPANIṢADBHĀṢYAM by Ānandatīrtha.

Foll. 21a—29a. Extent, 140 Granthas.
Same work as that described under D. No. 708.
Complete.

(i) कठवल्ल्युपनिषद्

KAṬHAVALLYUPANIṢAD.

Foll. 29a—39b. Extent, 250 Granthas. Printed.
Same work as that described under D. No. 334.
Complete.

(j) काठकोपनिषद्भाष्यम् by आनन्दतीर्थः
KĀTHAKOPANIṢADBHĀṢYAM by Ānandatīrtha.

Foll. 39b—49a. Extent, 240 Granthas. Printed.
Same work as that described under D. No. 348.
Complete.

(k) बृहदारण्यकोपनिषद्
BṚHADĀRAṆYAKOPANIṢAD.

Foll. 68—100. Extent, 730 Granthas. Printed.
Same work as that described under D. No. 633.
Wants the end. Otherwise complete.

(l) बृहदारण्यकोपनिषद्भाष्यम् by आनन्दतीर्थः
BṚHADĀRAṆYAKOPANIṢADBHĀṢYAM by Ānandatīrtha.

Foll. 101—165. Extent, 1,430 Granthas. Printed.
Same work as that described under D. No. 648.
Contains 5 Adhyāyas.

R. No. 5864

Palm leaf. 10¼ × 1½ inches. Foll. 69. Lines, 7 on a page. Nandināgarī. Injured. Extent, 1,207 Granthas.

Purchased in 1936-37 from Śrī P. Veṅkaṭaramaṇācār, Triplicane, Madras.

सङ्ग्रहरामायणटीका — रामगुणरत्नप्रकाशिका by श्रीपतिः
SAṄGRAHARĀMĀYAṆAṬĪKĀ—RĀMAGUṆARATNAPRAKĀŚIKĀ by Śrīpati.

The commentary on the text described under R. No. 448.
Contains 1 to 6 Sargās of Ayodhyākāṇḍa.

Beginning :

अयोध्याकथां वक्तुं तदुपोद्घातत्वे दशरथाभिवृद्धिं कथयति राम इति । राजा दशरथः ।

Colophon :

इति श्रीमत्सङ्ग्रहरामायणटीकायां रामगुणरत्नप्रकाशिकायां अयोध्याकाण्डे प्रथमः सर्गः ।

End :

अत्र श्लोके रामाननं हसितेषु बनवह्निस्वेन्दुत्वामृतपू . . त्वा सारोपाद्रूपकालङ्कारः । वसन्ततिलकं वृत्तम् ।
..

Colophon :

इति श्रीमत्संग्रहरामायणटीकायां रामगुणरत्नप्रकाशिकायां अयोध्याकाण्डे षष्ठः सर्गः ।

R. No. 5865

Palm leaf. 7¼ × 1½ inches. Foll. 45. Lines, 9 on a page. Nandinâgari. Injured. Extent, 810 Granthas. Text printed.

Purchased in 1936–37 from Śrī P. Veṅkaṭaramaṇācar, Triplicane, Madras.

मणिमञ्जरी by नारायणः with व्याख्या by श्रीनिवासः

MAṆIMAÑJARĪ by Nārāyaṇa with commentary by Śrīnivāsa.

The text described under D. No. 11866.

Contains 5 to 8 Sargas.

Beginning :

ततः परमहंसा ये कृष्णाभीमानुशिक्षिताः ।
व्यासाश्रयादतिजाद्या वेदशास्त्राण्यवर्तयन् ॥

ततः श्रीकृष्णादीनां स्वर्गयानानन्तरं कृष्णभीमानुशिक्षिताः श्रीकृष्णभीमसेनाभ्यां अनुशिक्षिताः पूर्वं श्रीरामाञ्जनेयाभ्यां ।

End :

उपसर्गयोगेन वर्तमानार्थत्वं । उपसर्गेणधात्वर्थो बलादन्यत्र नीयते इति विद्यमानत्वात् । अत्रश्लेषालङ्कृतिः । "नानार्थसंश्रयः श्लेषोवर्ण्यावर्ण्योभयास्पदः । सर्वदोमाधवः पायात् सयोगंगामदीधरद् । इति लक्षणोदाहरणात् वृत्तं शार्दूलविक्रीडितम् । मसजास्ततः सगुरवः शार्दूलविक्रीडितमिति लक्षणोदाहरणाच्च ।

Colophon :

इति श्रीमत्कविकुलतिलकश्रीमत्रिविक्रमपण्डिताचार्यसुतश्रीमन्नारायणपण्डिताचार्यकृतप्रमेयमणिमञ्जरी व्याख्यासुप्रभामञ्जर्यां करिकेहलिकुलोत्पन्नश्रीनिवासाचार्यतनूजातश्रीनिवासविरचितायामष्टमः सर्गः ।

कर्कैहल्लिकुलोत्पन्न श्रीनिवासार्यसूनुना ।
सन्मुदे श्रीनिवासेन सुप्रभामञ्जरी कृता ॥
प्रमेयमणिमञ्जरी विवृतिसुप्रभामञ्जरी ।
कृताञ्जनधरापते श्चरणकञ्जसेवादरात् ॥
मया सुजनतुष्टये सकलबाल धीश . . . चै
गुरोः परनिषेवणप्रभवशेमुषी संपदा ॥
आर्याकार्ययशोराशिवारिराशिसुधाकरम् ।
वन्देहं श्रीमदश्वत्थ नारायणगुरुं मुदे ॥
येनैकादशवारं व्याख्यातं मध्वशास्त्रमान्तं तम् ।
कर्कैहल्लि कुलोत्थं सत्तातं श्रीनिवासगुरुमीडे ॥

R. No. 5866

Palm leaf. 18 × 1½ inches. Fol. 166. Lines, 8 on a page. Nandinâgarî. Injured. Extent, 7,304 Granthas. Printed.

Purchased in 1936-37 from Śrī P. Veṅkaṭaramaṇācar, Triplicane, Madras.

महाभारततात्पर्यनिर्णयः by आनन्दतीर्थः
MAHĀBHĀRATATĀTPARYANIRṆAYAḤ by Ānandatīrtha.

Same work as that described under D. No. 4824.

Contains 1 to 31 Adhyayas, 32nd incomplete.

R. No. 5867

Palm leaf. 18 × 1½ inches. Fol. 107. Lines, 9 on a page. Nandinâgarî. Injured. Extent, 5,296 Granthas.

Purchased in 1936-37 from Śrī P. Veṅkaṭaramaṇācār, Triplicane, Madras.

संग्रहरामायणटीका —रामगुणरत्नप्रकाशिका by श्रीपतिः
SAṄGRAHARĀMĀYAṆAṬĪKĀ-RĀMAGUṆARATNAPRAKĀŚIKĀ by Śrīpati.

Same work as that described under R. No. 5864.

Contains Bālakāṇḍa and Āraṇyakāṇḍa.

Beginning :

यःकौसल्यालवालः श्रुतिविततपदः चारुसीतालतेतो

बाहुस्कन्धे विराज त्करचरणदलः सद्गुणानाक्षिपुष्पः ।

नित्यश्रेयः फलाढ्यो दशरथसुरराड . . . . द्विजेन्द्रैः

श्रेयः सोन्यादुदारो मरूद्वनपरो रामकल्पद्रुमोऽस्मान् ॥

इह खलुविविध वासना तरङ्गपरम्परापारावारनिमग्नान् तदुत्तारणो पायानभिज्ञान् जनान् श्रीरामकथानां . . . .

Colophon :

इति श्रीमद्व्यासतीर्थ श्रीमच्चरणशिष्य विविधसंसाराब्धितरण शमदमादिगुणमणिगणशालि श्रीलक्ष्मीकान्ततीर्थश्रीपादकरकरालसंजातेन श्रीपतियतिना विरचितायां श्रीमत्संग्रहरामायणटीकायां रामगुणरत्नप्रकाशिकायां बालकाण्डे अष्टमः सर्ग । बालकाण्डः समाप्तः ।

End :

मारीचो मारीतो भूत्वा कनकमृगतया लक्ष्मणाह्वानकारी शिक्षादक्षेण बालीयतश्रमजल वृत्केवलालोक इति संख्यानवहरेर्याति नियम इत्यर्थः ।

Colophon :

इति श्रीमत्संग्रहरामायणटीकायां रामगुणरत्नप्रकाशिकायां आरण्यकाण्डे षष्ठः सर्गः । श्रीआरण्यकाण्डः समाप्तः

R. No. 5868

Palm leaf. 18 × 1¾ inches. Foll. 246. Lines, 8 on a page. Nandinâgari. Injured. Extent, 9,840 Granthas. Printed.

Purchased in 1936-37 from Śrī P. Veṅkaṭaramaṇācār, Triplicane, Madras.

बृहदारण्यकभाष्यटीका by रघूत्तमयतिः ।

BṚHADĀRAṆYAKABHĀṢYAṬĪKĀ by Raghūttamayati.

This is a commentary by Raghūttamayati, on the Bṛhadāraṇyakabhāṣya of Ānandatīrtha.

Wants the end.

Beginning :

लक्ष्मीपतिं सुखमुखैरखिलै र्गुणौघैः पूर्णं व्यपेतनिखिलाघमचिन्त्यशक्तिम् ।
प्राणादिसर्वजगतो जनिपूर्वहेतुं मोक्षैकहेतुमनिशं प्रणमामि विष्णुम् ॥

निखिलाद्वैतसिद्धान्तप्राप्ताज्ञानविनाशकः ।
श्रीमदाचार्यसूर्योऽयं दद्यात्तत्त्वप्रकाशनम् ।

वाग्वज्रेणाच्छिनद्योतकृदतिविवदद्वादि सन्दोहमू
भूत्पक्षान् श्रीमन्द्रेण प्रमथनमकरोन्मध्वसिद्धान्तवार्धेः ॥
सम्प्राप्याथो सुधांगोनिखिलसुमनसः पाययामासमुक्त्यै
तं मूर्ध्ना श्रीजयार्यं सपदिबहुदशं संयमीन्द्रं नमामि ॥

येन वेदान्तभाष्याणि विवृतानि महात्मना ।
तं वन्दे व्यासतीर्थाख्यं वेदान्तार्थप्रसिद्धये ॥

योध्यापयित्वा वेदांश्चमध्व सिद्धान्त मादिशत् ।
न्यासं प्रादाद्धरेः प्रीत्यै रघुवर्यगुरुं भजे ॥

यत्काण्वोपनिषद्भाष्यं पूर्णप्रज्ञाविनिर्मितम् ।
तत्कृपालवमाश्रित्य व्याख्यास्ये तद्यथामति ॥

इहामुत्र फलभोगविरक्तस्य शमदमादिमतो मुमुक्षोरधिकारिणो अनिष्ट-निवृत्तेः परमानन्दावाप्तेश्च साधनत्वेन प्रवृत्तां काण्वीमुपनिषदमन्यैरन्यथा व्याख्यातत्वेनाप्रवृत्तामिव मन्यमानो यथावद्व्याचिख्यासुर्भगवानान्दतीर्थमुनिर्वि-लीनप्रकृतितयान्तरायविधुरोप्यनवरतमीश्वरप्रवणकरणवृत्तिरपि नारायणप्रणा-मादिकं प्रारिप्सितस्यानंतरायपरिसमाप्तेः प्रचयस्य च हेतुतया अविगीतशिष्टा-चारपरम्परादिनावगतमवश्यं करणीयं शिष्यान् ग्राहयितुं ग्रन्यादौ निबध्नाति ॥ प्राणादेरिति ।

End :

दधासीति । हे भार्ये त्वमिधासि स्तूयसे । मोक्ष मैत्रावरुणिः मित्रावरुणनामक भगवद्भयार्थज्ञानभूता हे दीक्षे आरब्धा . . . . . . या रुदती ।

. . . .

R. No. 5869

Palm leaf. 15 × 1½ inches. Foll. 83. Lines, 7 on a page. Nandināgarī. Good. Extent, 2,324 Granthas.

Purchased in 1936-37 from Śrī P. Veṅkaṭaramaṇācār, Triplicane, Madras.

गदाधरीयटीका—न्यायरत्नम् by रघुनाथः

GADĀDHARĪYAṬĪKĀ—NYĀYARATNAM by Raghunātha.

Same work as that described under D. No. 4084.

Contains Caturdaśalakṣaṇī and a portion of Siddhāntalakṣaṇa.

R. No 5870

Palm leaf. 18 × 1½ inches. Foll. 98. Lines, 5 on a page. Nandināgarī. Good.

Purchased in 1936-37 from Śrī P. Veṅkaṭaramaṇācār, Triplicane, Madras.

(a) अलङ्कारमञ्जरीटीका—मधुधारा by सुमतीन्द्रयतीन्द्रः ।

ALAṄKĀRAMAÑJARĪṬĪKĀ—MADHUDHĀRĀ by Sumatīndra-yatīndra.

Foll. 1a—71b. Extent, 1,775 Granthas.

Similar work as that described under R. No. 2152.

Incomplete. Breaks off Śleṣaprakaraṇa.

Beginning :

यत्कर्तृकं जगदिदं यदनुप्रविष्टं
यस्मिन् मुहुर्निविशते यदनन्यनाथम् ।
तं प्राणुवीमहि महीतनयाकटाक्ष-
पीयूषवीचिरचिताप्लव मादिदेवम् ॥

. . . .

. . . .

प्राचामुपा चामदलं क्रियात्त
वाचा मनीराणि मतामृतानि ।
सुधीन्द्रयोगी तदिदं कृतालं-
कृपागमं न स्पृहयन्ति के वा ॥

श्रीवुमतीन्द्रयतीन्द्रो व्यतनोदतनीयसीमसीमगुणाम् ।
व्याख्यां मधुधाराख्यां विवृतालङ्कारमञ्जरीहृदयाम् ॥
आस्माकी सुकविमुदे स्यात्तदलङ्कारमञ्जरीविवृतिः ।
मधुधाराख्या पङ्कजसौरभ लक्ष्मीरिवालिहर्षाय ॥

End :

सकलावद्रातः प्रशान्तमोह इत्यत्र वाक्यगतः श्लेषः । तदन्यत्र यद्गत. । एते त्रयोपि श्लेषाः वर्णानामावापोद्वापाभ्यां विकृताः इरतारविकृताः । तत्र विकृतेषु केवलप्रकृतगोचरो यथा ।—

विराजचिविश्नो विभवार्चितांघ्रिः
श्रीज्या कृतांन्द्री दशाननान्तः ।
अखण्डरूपोपमनारिदासो
देवो नदेवोस्तु सलक्ष्मणांकः ॥
वराह गरुडौ चिह्न यस्य सः विभवैः ।

(b) तर्कसंग्रहव्याख्या—दीपिका by अन्नंभट्टः ।
TARKASAṄGRAHAVYĀKHYĀ—DĪPIKĀ by Annambhaṭṭa.

Foll. 72—82. Extent, 250 Granthas. Printed.
Same work as that described under D. No. 4154.
Contains Śabdakhaṇḍa only.

(c) अलङ्कारमञ्जरी
ALAṄKĀRAMAÑJARĪ.

Foll. 86—98. Extent, 300 Granthas.
Similar to the work described under R. No. 2152.

Beginning :

वन्देमह्यनिशं निजाङ्कविलसन्नीरेरुहाक्षीमणी
जाग्रद्गात्ररुचि विहंग वरिणी(?)व्यूढांसरूढासिकिम् ।
तं कञ्चिन्महिमान मुज्वलपदांभोजद्वयीध्यायिनः
सर्वाधानपरोक्षयत्यतितरां यस्य स्मृतिर्वाञ्छितान् ॥

End :

अधिकृत्यास्मदाचार्यान् विजयीन्द्रयतीश्वरान् ।
प्रवृत्तेयमनुग्राह्या मूर्धा लङ्कारमञ्जरी ॥

R. No. 5871

Palm leaf. 15 × 1½ inches. Foll. 72. Lines, 7 on a page. Nandināgarī. Injured. Extent, 2,016 Granthas.

Purchased in 1936-37 from Śrī P. Veṅkaṭaramaṇācar, Triplicane, Madras.

वेङ्कटगिरिमहात्म्यम्

VEṄKAṬAGIRIMĀHĀTMYAM.

Similar to the work described under D. No. 2522.
Contains 1 to 13 Adhyāyas.

Beginning :

शौनक उवाच—

कथितं रङ्गमाहात्म्यं त्वया हस्तिगिरीशितुः ।
जगन्नाथस्य वै विष्णो र्माहात्म्य मतुलं मुनेः ॥
इदानीं श्रोतु मिच्छामि माहात्म्यं वेङ्कटेशितुः ।

श्रीसूतः—

सालुप - - या ब्रह्मन् चरितं वेङ्कटेशितुः ।
याद्या श्रुतं मया पूर्वं व्यासेनामिततेजसा ॥
तदद्याहं तथावक्ते सावधानमनाः शृणु ।

Colophon :

इति श्रीभविष्योत्तरपुराणे वेङ्कटगिरिमाहात्म्ये चतुर्युगपर्वतविभागो नाम प्रथमोऽध्यायः ।

End :

सारूप्यं च ददौ तस्य सभार्यस्य जगत्पतेः ।
नृपोऽतिदुःखसन्तप्तः कथं मे जगदीश्वरः ॥
सारूप्यं मे ददातीति तेन शोकं जगामह ।
सारूप्यं च ददौ देवो राज्ञस्तस्य महात्मनः ॥

Colophon :

इति श्रीभविष्योत्तरपुराणे वेङ्कटगिरिमहात्म्ये वों ट्मिा नृपस्य सारूप्यमुक्तिदानं नाम त्रयोदशोऽध्यायः ।

R. No. 5872

Palm leaf. 12 × 1¾ inches. Foll. 129. Lines, 8 on a page. Nandināgarī. Injured. Extent, 3,855 Granthas. Printed.

Purchased in 1936-37 from Śrī P. Veṅkataramaṇācār, Triplicane, Madras.

बृहदारण्यकोपनिषद्भाष्यम् by आनन्दतीर्थः
BṚHADĀRAṆYĀKOPANIṢADBHĀṢYAM by Ānandatīrtha.

Same work as that described under D. No. 648.
Contains 1 to 7 Adhyāyas.

R. No. 5873

Palm leaf. 16¼ × 1½ inches. Foll. 65. Lines, 6 on a page. Nandināgarī. Good.

Purchased in 1936-37 from Śrī P. Veṅkataramaṇācār, Triplicane, Madras.

(a) सिद्धान्तमुक्तावली by विश्वनाथपञ्चाननः
SIDDHĀNTA MUKTĀVALĪ by Viśvanāthapañcānana.

Foll. 1a—11b. Extent, 297 Granthas. Printed.
Same work as that described under D. No. 3938.
Contains Śabdakhaṇḍa only; wants the beginning.

(b) कारिकावली by विश्वनाथपञ्चाननः
KĀRIKĀVALĪ by Viśvanāthapañcānana.

Foll. 12—65. Extent, 1,430 Granthas. Printed.
Same work as that described under D. No. 3938.
Complete.

R. No. 5874

Palm leaf. 14½ × 1¾ inches. Foll. 250. Lines, 6 on a page. Nandināgarī. Injured.

Purchased in 1936-37 from Śrī P. Veṅkaṭaramaṇācār, Triplicane, Madras.

(a) सुधागद्यम्.
SUDHĀGADYAM.

Foll. 1a—2b. Extent, 48 Granthas.
Complete.

Beginning :

अखिलगुणगणखानिहरिपदनखघुघटितमुखारितमुरसुलविदेपदविचाराधि - करण जिज्ञास्यस्वरूप निर्धारक जन्माधिकरण . . . .

End :

अन्ये तु श्रोतृजनसकलवर्जनमोचिकास्वरवर्णपदवाक्यमहावाक्येषु अनिरुद्धप्रद्युम्नसंकर्षणवासुदेवनारायणादिका मां पान्तु पान्तु ।

Colophon :

इति सुधागद्यम् ।

(*b*) लघुतारतम्यटीका.

LAGHUTĀRATAMYAṬĪKĀ.

Foll. 5—8. Extent, 96 Granthas.
Complete.

Beginning :

विष्णुस्सर्वोत्तमोऽथ प्रकृतिरथ विधिप्राणनाथावथोक्ते-
ब्रह्माणी भारतीच द्विजफणिपमृडाश्च स्त्रियष्षट्च विष्णोः ।
सौपर्णी वारुणी पर्वतपतितनया चेन्द्रकामावथास्मात्
प्राणोऽयोऽथोऽनिरुद्धो रतिमनुगुरवो दक्षशच्यौ च पान्तु ॥

आदौ विष्णुः सर्वोत्तमः, तदनु प्रकृतिः महालक्ष्मीः ।

End :

अनन्तरं सौपर्णीं गरुडभार्यां अहिपतिदयितां शेषपत्नीं नाम्ना वारुणीं तां प्रसिद्धां रुद्रपत्नीमुमां वन्दे । तदनन्तरमिन्द्रादीन् काममुख्यान् सकलदेवांस्तद्गुरून् तेषते गुरवश्च तद्गुरवः श्रीमदानन्दतीर्थादिगुरून् मद्गुरूंश्च वन्दे ।

Colophon :

इति लघुतारतम्यटीका संपूर्णा ।

(*c*) ब्रह्मसूत्रानुव्याख्यानटिका—न्यायसुधा by जयतीर्थ ।

BRAHMASŪTRĀNUVYĀKHYĀNAṬĪKĀ—NYĀYASUDHĀ by Jayatīrtha.

Foll. 9—250. Extent, 6,000 Granthas. Printed.
Same work as that described under R. No. 875.
Contains 1st Adhyāya.

R. No. 5875

Palm leaf. 16½ × 1½ inches. Foll. 59. Lines, 7 on a page. Nandināgari. Injured. Extent, 1,638 Granthas. Printed.

Purchased in 1936–37 from Śrī P. Veṅkaṭaramaṇācār, Triplicane, Madras.

ब्रह्मसूत्रानुव्याख्यानटीका—न्यायसुधा by जयतीर्थः ।

BRAHMASŪTRĀNUVYĀKHYĀNAṬĪKĀ-NYĀYASUDHĀ by Jayatīrtha.

Same work as that described under R. No. 875.

Contains 2nd Adhyāya. Wants the beginning.

R. No. 5876

Palm leaf. 14¼ × 1¼ inches. Foll. 55. Lines, 10 on a page. Nandināgarī. Injured. Extent, 2,200 Granthas.

Purchased in 1936—37 from Śrī P. Veṅkaṭaramaṇacārya, Triplicane, Madras.

वेङ्कटगिरिमाहात्म्यम्.

VEṄKATAGIRIMĀHĀTMYAM.

Same work as that described under R. No. 5871.

Contains 1 to 13 Adhyāyas. Taken from Bhaviṣyottarapurāṇa—56 to 62 left blank, 63 and 64 contains some Rāmāyaṇaślokās.

R. No. 5877

Palm leaf. 16¾ × 1¼ inches. Foll. 76. Lines, 5 on a page. Nandināgarī. Extent, 1,520 Granthas. Printed.

Purchased in 1936-37 from Śrī P. Veṅkaṭaramaṇācār, Triplicane, Madras.

व्युत्पत्तिवादः by गदाधरः

VYUTPATTIVĀDAḤ by Gadādhara.

Same work as that described under D. No. 4290.

Incomplete.

R. No. 5878

Palm leaf. 15¼ × 1¼ inches. Foll. 152. Lines, 6 on a page. Nandināgarī. Good. Extent, 4,131 Granthas. Printed.

Purchased in 1936-37 from Śrī P. Veṅkaṭaramaṇācār, Triplicane, Madras.

भागवततात्पर्यनिर्णयः by आनन्दतीर्थः

BHĀGAVATATĀTPARYANIRṆAYAḤ by Ānandatīrtha.

Same work as that described under D. No. 4823.

Complete.

Foll. 78 to 83 and 151 and 152 contains Bhāgavatatātparyaprakāśikā of Śrinivāsa and Bhāgavatatātparyadīpikā of Narahatyācārya.

R. No. 5879

Palm leaf. 8½ × 1¼ inches. Fol. 35. Lines, 8 on a page. Nandinâgari. Injured.

Purchased in 1936–37 from Śrī P. Veṅkaṭaramaṇācār, Triplicane, Madras.

(a) विष्णुतत्वनिर्णयः by आनन्दतीर्थः

VIṢṆUTATTVANIRṆAYAḤ by Ānandatīrtha.

Foll. 1a—35. Extent, 560 Granthas. Printed.

Same work as that described under D. No. 4840.

Complete in 3 Paricchēdas.

Foll. 36—41. Contains a portion of Ānandatīrtha's Karmanirṇaya which is already printed.

(b) सुदर्शनमन्त्रः

SUDARŚANAMANTRAḤ.

Foll. 42—44a. Extent, 28 Granthas.

Same work as that described under D. No. 7539.

Reading is slightly different.

R. No. 5880

Palm leaf. 16¾ × 1¼ inches. Fol. 63. Lines, 7 on a page. Nandinâgari. Extent, 1,984 Granthas. Printed.

Purchased in 1936–37 from Śrī P. Veṅkaṭaramaṇācār, Triplicane, Madras.

विष्णुतत्वनिर्णयव्याख्या by जयतीर्थः

VIṢṆUTATTVANIRṆAYAVYĀKHYĀ by Jayatīrtha.

Same work as that described under D. No. 4843.

Contains 3 Paricchedās.

R. No. 5881

Palm leaf. 11¾ × 1¼ inches. Fol. 64. Lines, 8 on a page. Nandinâgari. Much injured. Extent, 1,792 Granthas. Printed.

Purchased in 1936–37 from Śrī P. Veṅkaṭaramaṇācār, Triplicane, Madras.

ब्रह्मसूत्रानुव्याख्यानम् by आनन्दतीर्थः

BRAHMASŪTRĀNUVYĀKHYĀNAM by Ānandatīrtha.

Same work as that described under D. No. 4819.

Complete.

R. No. 5882

Palm leaf. 15 × 1⅜ inches. Fol. 69. Lines, 7 on a page. Nandināgarī. Injured.
Extent, 1,932 Granthas.

Purchased in 1936-37 from Śrī P. Veṅkaṭaramaṇācār, Triplicane, Madras.

तन्त्रसारविवृतिः by वेङ्कटनरसिंहः

TANTRASĀRAVIVṚTIḤ by Veṅkaṭanarasiṁha.

Similar to the work described under R. No. 870.

Contains 1 to 4 Adhyāyas.

Beginning :

प्रणम्य कमलानाथं पूर्णबोधान् गुरूनपि ।
करिष्ये तन्त्रसारस्य व्याख्यानं नातिविस्तरम् ॥

श्रीनारायणपूजादिप्रकारं मन्त्रनिरूपणपूर्वकं निरूपयितुकामो भगवानाचार्यो नारायणस्तुतिरूपं मङ्गलमाचरति—जयतीति । जयतिरुत्कृष्टोवर्तते ।

Colophon :

इति श्रीमत्पूज्यपादानां श्रीवासुदेवाचार्यवर्याणां [ ]त्येगानन्दतीर्थाचार्यवर्याणां तनूजेनानन्ताचार्य वर्याणां पुत्रेण वेङ्कटनरसिंहेन विरचितायां श्रीमत्तन्त्रसारविवृतौ प्रथमोऽध्यायः ।

End :

संपूर्णसद्गुणतनुं सकलागमैक
गम्यं सदा सकलदोषविहीन मन्यम् ।
स्थित्युद्भवप्रलयकारण मस्य सर्व
विश्वस्य विठ्ठलमजं प्रणतोऽस्मि नित्यम् ॥

श्रीमदानन्दतीर्थार्यान् तथा जयमुनीन् गुरून् ।
नरसिंहाचार्यवर्यांश्च वन्दे सर्वगुरूनपि ॥

संपूर्णबोधगुरुकल्पतरुप्रबुद्ध
सुज्ञानरूपफलमुक्त महानिशं मे ।
भूयादनादिस्थितिततनोरनन्त
कालेपि सौख्यदमिदं परमादरेण ॥

कृतेयं प्रीतये विष्णो स्तन्त्रसारार्थचन्द्रिका
पूर्णबोधार्यवर्याणां वासुदेवेन सूनुना ॥
पूर्णागण्यगुणोदारं निश्शेषावद्यवर्जितम् ।
अशेषाम्नायहृद्दीपं वन्दे विठ्ठल मिष्टदम् ॥
वेङ्कटादिनृसिंहेन गुरोर्व्याख्यानगर्भिना ।
विवृतिस्तन्त्रसारस्य कृतानन्तार्यसूनुना ..

Colophon .

इति श्रीमत्पूज्यपादानां श्रीवासुदेवाचार्यवर्याणां शिष्येण अनन्ताचर्यवर्याणां तनुजेन (अनन्ताचार्याणां पुत्रेण ?) वेङ्कटनरसिंहेन विरचितायां श्रीमत्तन्त्रसारविवृतौ चतुर्थोऽध्यायः ।

R. No. 5883

Palm leaf. 13 × 1½ inches. Fol. 56. Lines, 8 on a page. Nandināgarī. Injured. Extent, 1,782 Granthas. Printed.

Purchased in 1936-37 from Śrī P. Veṅkaṭaramaṇācār, Triplicane, Madras.

भगवद्गीतातात्पर्यनिर्णयः by आनन्दतीर्थः

BHAGAVADGĪTĀTĀTPARYANIRṆAYAḤ by Ānandatīrtha.

Same work as that described under R. No. 455.

Complete.

R. No. 5884

Palm leaf. 16 × 1½ inches. Fol. 68. Lines, 6 on a page. Nandināgarī. Injured. Extent, 1,632 Granthas. Printed.

Purchased in 1936-37 from Śrī P. Veṅkaṭaramaṇācār, Triplicane, Madras.

भगवद्गीताभाष्यम् by आनन्दतीर्थः

BHAGAVADGĪTĀBHĀSYAM by Ānandatīrtha.

Same work as that described under D. No. 2080.

R. No. 5885

Palm leaf. 19 × 1¼ inches. Foll. 82. Lines, 8 in a page. Nandināgarī. Injured. Extent, 2,280 Granthas. Not printed.

Purchased in 1936–37 from Śrī P. Veṅkaṭaramaṇācār, Triplicane, Madras.

अनुव्याख्यानन्यायविवरणटीका-

न्यायप्रकाशिका by आनन्दतीर्थः

ANUVYĀKHYĀNANYĀYAVIVARAṆAṬĪKĀ-NYĀYAPRAKĀŚIKĀ by Ānandatīrtha, son of Viṭṭhalācārya.

Foll. 1*a*—82*a*. 82*b* is left blank.

This is a commentary on the Anuvyākhyāna Nyāyavivaraṇa of Ānandatīrtha which is described under D. No. 4822.

Complete.

Beginning :

पद्मापतिपदाम्भोजपांसवः पावयन्तु माम् ।
परमादरतः पूर्णप्रज्ञाचार्यसुपूजिताः ॥
जयतीर्थार्यरचितां सार्धपादद्वयोपगाम् ।
सन्न्यायविवृतेर्व्याख्यां व्याख्यायोपरिगामपि ।
दोषसन्न्यायविवृतिं रघूत्तममुनिश्वरैः ।
व्याख्यातां भावबोधाख्यैरपि संग्रहलालसः ।
तद्ग्रन्थ मुपजीव्यैव व्याख्यातु मद्दमुत्सहे ।
कृपाम . . . . रघूत्तमः ॥
इहाधिकरणेषु क्रमेण पूर्वपक्षन्यायाः सङ्क्षेपेणोक्ताः ।
बाहुल्यं लिङ्गशब्दाना मनुक्तिश्च विरुद्धता ।
अदृष्टिरन्वयाभावो विपरीतश्रुतिभ्रमः ।
लिङ्गावकाशराहित्यप्रपस्ताद्दग्द्वयं तथा ।
बहुताढकत्व मुक्तस्य विरोधोऽर्था त्तथागतिः ।
समस्तमेतदित्यत्र पूर्वपक्षेषु युक्तयः ॥ इति ।

तानिदानीं विवृण्वन्नाह बाहुल्यं लिङ्गशब्दानामिति प्रथमाधिकरणे पूर्वपक्षन्यायं विवृणोति यस्मिन्धीरिति ।

Colophon :

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितस्य श्रीमन्न्यायविवरणस्य टीकायां विठ्ठलाचार्यतनूजेनानन्दतीर्थाख्येन कृतायां न्यायप्रकाशिकायां प्रथमाध्यायस्य तृतीयः पादः ।

End :

आनन्दतीर्थसन्नाम्ना विठ्ठलाचार्यजन्मना ।
सन्न्यायविवृतेर्व्याख्या कृता न्यायप्रकाशिका ॥
क्वाहं सुमन्दधिषणः क्कुपि कर्चैत
च्छास्त्रं सुधादिविबुधै रधिगम्य . . . . ।
. . . . . यदहं प्रवृत्तः
तत्क्षाम्यतां सुरवरै रपराधजातम् ।
श्रीमन्न्यायप्रकाशोऽयं सूत्रकाराय विष्णवे ।
समर्पितो मया तेन प्रीयतां श्रीरमापतिः ॥
श्रीमदानन्दतीर्थाख्यहृदयाम्भोजवासिने ।
. . . . . भोजराजहंसाय विष्णवे ॥

Colophon :

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितस्य श्रीमन्न्यायविवरणस्य टीकायां विठ्ठलाचार्यवर्यतनूजेनानन्दतीर्थापरनामकेन विरचितायां न्याय प्रकाशिकायां चतुर्थाध्यायस्य चतुर्थः पादः ।

R. No. 5886

Palm leaf. 8¼ × 2 inches. Foll. 163. Lines, 12 in a page. Nandināgarī. Injured. Extent, 4,192 Granthas.

Purchased in 1936–37 from Śrī P. Veṅkaṭaramaṇācār, Triplicane, Madras.

संग्रहरामायणम् by नारायणपण्डितः

SAṄGRAHARĀMĀYAṆAM by Nārāyaṇapaṇḍita.

Same work as that described under R. No. 448.

Complete.

R. No. 5887

Palm leaf. 17¾ × 1½ inches. Fol. 70. Lines, 5 in a page. Nandināgarī. Injured.

Purchased in 1936–37 from Śrī P. Veṅkaṭaramaṇācār, Triplicane, Madras.

(a) ईशावास्योपनिषद्भाष्यटीका by जयतीर्थः
ĪŚĀVĀSYOPANIṢADBHĀṢYAṬĪKĀ by Jayatīrtha.

Foll. 1a—12b. Extent, 288 Granthas. Printed.

Same work as that described under R. No. 493.

Complete.

(b) ईशावास्योपनिषदर्थसंग्रहः by राघवेन्द्रयतिः
ĪŚĀVĀSYOPANIṢADARTHASAṄGRAHAḤ by Rāghavendrayati.

Foll 13a—17a, 17b left blank. Extent, 114 Granthas. Printed.

In this work, Rāghavendrayati gives in brief the idea contained in the Īśāvāysopaniṣad.

Complete.

Beginning :

श्रीप्राणपतिमानम्य पूर्णबोधादिदेशिकान् ।
ईशावास्योपनिषदः करिष्याम्यर्थसंग्रहम् ॥

अस्या उपनिषदः स्वायम्भुवो मनुः ऋषिः, यज्ञनामा हरिर्देवता, अनक्षरादि यथायोग्यं छन्दो ज्ञेयम् । अनेक्षदित्यादिना तत्त्वं विवक्षरुपदिष्टं तत्त्वं, अधिकारिणा . . . ह्य भवतिष्ठते । नान्यस्येति उपनिषदधिकारसिद्ध्यर्थं विच्छिन्नविषयतृष्णत्वं तावदाद्येन मन्त्रेण सयुक्तिकं विवत्ते ईशेति ।

End :

समस्तगुणपूर्णाय दोषदूराय विष्णवे ।
नमः श्रीप्राणनाथाय भक्ताभीष्टप्रदायिने ॥
ईशावास्योपनिषदो भाष्यसूक्तार्थसंग्रहः ।
राघवेन्द्रेण यतिना कृतोऽयं शिष्ययाच्ञया ।

Colophon :

इति श्रीराघवेन्द्रयतिकृतेशावास्योपनिषत्संग्रहार्थः समाप्तः ।

The Manuscript is said to have been copied on the month of Kartikai in the year Hevilambi.

(c) तलवकारोपनिषद्भाष्यविवरणम् by व्यासतीर्थभिक्षुः

TALAVAKĀROPANIṢADBHĀṢYAVIVARAṆAM by Vyāsatīrtha-bhikṣu.

Foll. 18a—21a. Extent, 100 Granthas. Printed.

This is a commentary, by Vyāsatīrtha, on the Talavakāropaniṣad-bhāṣya of Ānandatīrtha.

Beginning :

जडाजडात्मकं विश्वं कृत्वाधिष्ठाय संहरन् ।
स्वभावात्क्रीडते यस्तं वन्दे श्रीमध्ववल्लभम् ॥
योऽसुरा नजयद्देवहृद्यस्थ स्तदर्थतः ।
ददौ चाभीष्ट मिष्टेभ्य स्तं वन्दे मध्ववल्लभम् ॥

तलवकारोपनिषदं यथावद् व्याचिख्यासुर्भगवानानन्दतीर्थमुनि स्तदुक्तगुणैरूपश्लोकयन्नारायणं प्रणमति अनन्तेति

End :

मङ्गलावसानस्य शास्त्रस्य प्रचयादिहेतुत्वात् भाष्यं समाप्यअन्तेऽपि स्वेष्टदेवतास्तुतिनमनरूपं मङ्गल माचरति य इति ।

यत्पदं मुनिभिर्ध्यातं वेदान्तश्रान्तमानसैः ।
तं वन्दे परमात्मानं विष्णुं श्रीमध्ववल्लभम् ॥

Colophon :

इति श्रीमदानन्दतीर्थभगवत्पादविरचित तलवकारोपनिषद्भाष्यस्य विवरणं श्रीमज्जयतीर्थपूज्यचरणशिष्यव्यासतीर्थभिक्षुविरचितं समाप्तम् ॥

(d) माण्डूक्योपनिषद्भाष्यटीका by व्यासतीर्थः

MĀṆḌŪKYOPANIṢADBHĀṢYAṬĪKĀ by Vyāsatīrtha.

Foll. 21a—30b. Extent, 260 Granthas. Printed.

This is a commentary, by Vyāsatīrtha, on the Māṇḍūkyopaniṣad-bhāṣya of Ānandatīrtha.

Beginning :

नेत्राद्यादिस्थितोऽवस्था जाग्रदाद्याः प्रवर्तयन् ।
विश्वादिरूपी भगवान् यस्तंवन्दे श्रियः पतिम् ।

इहामुत्रभोगविरक्तस्य शमदमादिमतो मुमुक्षो रधिकारिणोऽनिष्ट-निवृत्तीष्टावाप्तिसाधनभगवत्प्रतिपादिकां माण्डूकोपनिषदं यथावद्व्याचिख्यासु-र्भगवानानन्दतीर्थमुनिः समीहितसमाप्त्यादिसाधनतया अवसितं मङ्गला-चरण मादौ कार्यमिति सूचयन् तदुक्तगुणवन्त मुपश्लोकयन् प्रणमतिपूर्णेति :—

End :

निर्विशेषोपीन्द्रार्जुनादिव द्विशेषरहितोऽपि विश्वादिचतूरुपेण चतुर्धासन् जाग्रदादिचतुर्धा व्यवहारमागित्यशेषमतिमङ्गलम् ।

यःसर्वजीवनेत्रादौ स्थित्वावस्थाः प्रवर्तयन् ।
मोक्षदश्च रमानाथं वन्दे तं मध्ववल्लभम् ॥

Colophon :

इति श्रीमदानन्दतीर्थभगवत्पादविरचितमाण्डूकोपनिषद्भाष्यटीका व्यास-तीर्थमुनिविरचिता समाप्ता ।

(*e*) षट्प्रश्नोपनिषद्भाष्यविवरणम् by जयतीर्थः
ṢAṬPRAŚNOPANIṢADBHĀṢYAVIVARAṆAM by Jayatirtha.

Foll. 31*a*—46*b*. Extent, 416 Granthas. Printed.

This is a commentary, by Jayatirtha, on the Ṣatpraśnopaniṣad-bhāṣya of Ānandatirtha.

Beginning :

पान्तु नः पद्मनाभस्य श्रीपदाम्बुजरेणवः ।
कमलाकबरीभारसुरभीकरणोद्यताः ॥

इहखलु संसारपारावारे निपतित मधिकारिजनं जननीतनयमिव पर-मात्मतत्त्वज्ञानप्लवेनोद्दिधीर्षु रिय माथर्वणीब्राह्मणोपानिषत् , इति कर्तव्य तामन्तरेण न तत्त्वज्ञानकारणता मापाद्यते । अतः तदितिकर्तव्यतारूप-न्यायगर्भं भाष्यं करिष्यन्नाचार्यः प्रारिप्सितपरिसमाप्त्यादिप्रयोजना मेतदुप-निषत्प्रतिपाद्यदेवताप्रणतिमादौ निबध्नाति नम इति ।

End :

अत एव भाष्यकारोऽप्यन्ते च भगवत्प्रणतिं निबध्नातिनम इति ।

वचनप्रसूनमाला जयतीर्थाख्येन भि णा रचिता ।
ध्रियतां हृदये सदये कमलामहिलेन पुरुषेण ॥

Colophon :

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितस्य षट्प्रश्नोपनिषद्भाष्यस्य विवरणं जयतीर्थभिक्षुविरचितं समाप्तम् ।

(*f*) आथर्वणोपनिषद्भाष्यटीका by व्यासतीर्थः

ĀTHARVAṆOPANIṢADBHĀṢYAṬĪKĀ by Vyāsatīrtha.

Foll. 47*a*—56*a*, 56*b* left blank. Extent, 240 Granthas. Printed.

This is a commentary, by Vyāsatīrtha, on the Ātharvaṇopaniṣadbhāṣya of Ānandatīrtha. Ātharvaṇopaniṣat is also known as Muṇḍakopaniṣat.

Complete.

Beginning :

संपूर्णसंविदानन्दसुखसर्वगुणात्मकम् ।
रमारमण मिष्टार्थं प्रपद्ये मध्ववल्लभम् ॥

आथर्वणीं मन्त्रोपनिषदं यथावत् व्याचिख्यासुर्भगवानानन्दतीर्थमुनि निर्विघ्नपरिसमाप्तिहेतुभूतं तदुक्तगुणवद्भगवत्स्तुतिनतिरूपमङ्गलमादा वाचरति आनन्दमिति ।

End :

समापितभाष्यो भगवानानन्दतीर्थमुनिः भाष्यकरणप्रयोजनं सूचय न्भाष्यान्ते प्रणमति प्रीयतामिति ।

यां ब्रह्मादेरथर्वाख्यां विशामाप्यपरावराम् ।
. . . .
सुनिश्चिताश्च या विष्णुविषयाऽहं नमामि ताम् ॥

Colophon :

इति श्रीमदानन्दतीर्थभगवत्पादविरचितस्याथर्वणोपनिषद्भाष्यस्यटीका जयतीर्थ पूज्यचरणशिष्यव्यासतीर्थैकृता समाप्ता ॥

(*g*) काठकोपनिषद्भाष्यटीका by व्यासतीर्थ

KĀṬHAKOPANIṢADBHĀṢYAṬĪKĀ by Vyāsatīrtha.

Foll. 57*a*—67*b*. Extent, 280 Granthas. Printed.

Foll. 68—70 are left blank.

This is a commentary, by Vyāsatīrtha, on the Kāṭhakopaniṣadbhāṣya of Ānandatīrtha.

Beginning :

यत्पदं मुनिभिर्ध्यातं वेदान्तश्रान्तमानसैः ।
वन्दे तं परमात्मानं विष्णुं श्रीमध्ववल्लभम् ॥
योदेवः परमत्वेन सर्वदेवै रूपास्यते ।
हृदये वामनाख्यं तं वन्दे श्रीमध्ववल्लभम् ॥

इहामुत्रभोगविरक्तस्य शमदमादिमतो मुमुक्षो रधिकारिणोऽनिष्टनिवृत्ती-ष्टावाप्तिसाधनप्रतिपादिकां काठकोपनिषदं यथावत् व्याचिख्यासुर्भगवाना-नन्दतीर्थमुनिरादै मङ्गलाचरणं चिकीर्षितपरिसमाप्त्यादिकारण मित्याश-यवांस्तदुक्तगुणवत्तया भगवन्तं स्तुवन्प्रणमति । नमइति ।

End :

नमइति । प्रभविष्णवे प्रभवनशीलाये त्यशेषमतिमङ्गलम् ।

Colophon :

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितस्य काठकोपनिषद्भाष्यस्य टीका जयतीर्थपूज्यचरणशिष्यव्यासतीर्थविरचिता संपूर्णा ।

R. No. 5888

Palm leaf. 15 × 1¼ inches. Foll. 121. Lines, 5 in a page. Nandināgarī. Injured.

Purchased in 1936-37 from Śrī P. Veṅkaṭaramaṇācār, Triplicane, Madras.

(a) गदाधरीयटिप्पणम् —न्यायरत्नम् by रघुनाथः

GADĀDHARĪYAṬIPPAṆAM—NYĀYARATNAM by Raghunātha.

Foll. 1a—34b. Extent 578, Granthas. Printed.
Same work as that described under D. No. 4084.
Incomplete.

(b) सरसभारती by वादिराजः

SARASABHĀRATĪ by VĀDIRĀJA.

Foll. 35a—62b. Extent, 648 Granthas.
Same work as that described under R. No. 858 (b).
Complete in twelve vilāsas.

(c) ऋणमोचनस्तोत्रम् by वादिराजः
ṚṆAMOCANASTŌTRAM by Vādirāja.

Foll. 63a. Extent, 10 Granthas.

This contains stanzas addressed to Lord Nṛsimha and he, who utters these, will get released from debts of all kinds.

Complete.

Beginning :

श्रीदेवताकार्यसिद्ध्यर्थं सभास्तम्भसमुद्भवम् ।
श्रीनृसिंहमहावीरं नमामि ऋणमुक्तये ॥
लक्ष्म्यालिङ्गितवामाङ्गं भक्तानामिष्टदायकम् ।
श्रीनृसिंहमहावीरं नमामि ऋणमुक्तये ॥

End :

वेदान्तवेद्यं यज्ञेशं ब्रह्मरुद्रादिसंस्तुतम् ।
श्रीनृसिंहमहावीरं * * * * ॥
य इदं पठते नित्यमृणमोचनसंज्ञकम् ।
अनृणी जायते सद्यः धनं शीघ्रमवाप्नुयात् ॥

Colophon :

इति श्रीवादिराजपूज्यचरणविरचितमृणमोचनस्तोत्रं संपूर्णम् ।

(d) हयग्रीवस्तोत्रम् by वादिराजः
HAYAGRĪVASTŌTRAM by Vādirāja.

Foll. 63a and b. Extent, 20 Granthas.

This contains stanzas in praise of Hayagriva, a form of Viṣṇu.

Complete.

Beginning :

रमारमणमध्वादिदेशिकश्रीहृदब्जग ।
हयग्रीव दयालो मे प्रार्थनां शृणु सादरम् ॥
अयोग्यविषये स्वामिन्सर्वदा न मनोभवेत् ।
चाञ्चल्यं मूलतश्छिन्धि आशां हर सुदूरतः ॥

End :

प्रार्थनादशकं चैत त्रिकाले यः पठेन्नरः ।
तस्याभीष्टं हयास्योऽसौ दत्वा रक्षति सर्वदा ॥

Colophon :

इति श्रीवादिराजपूज्यचरणविरचितं हयग्रीवप्रार्थनास्तोत्रं संपूर्णम् ।

(e) विष्णुस्तुतिः

VIṢṆUSTUTIḤ.

Foll. 64a—66b. Extent, 55 Granthas.

This contains stanzas in praise of Viṣṇu.

Incomplete.

Beginning :

सत्यं ज्ञानमनन्तमानन्दं ब्रह्म सर्वशक्त्यैकम् ।
सर्वदेवैरीड्यं विष्ण्वाख्यं सर्वधर्मसु नेक्षम् ॥
आदित्यसंज्ञिताद्विष्णोः श्रुत्वा ब्रह्मा यथा हरिम् ॥
तुष्टाव तत्प्रकारेण वरुणोक्तेन वै भृगुः ।
विष्णु मस्तौ त्तथा . . . . . शन्नोमित्रादिका श्रुतिः ॥

End :

तेनामृतेन सिक्ताङ्गं तेनव्याप्नोयतस्सदा ।

इत्याह मन्त्रकृक् पूर्वं त्रिशङ्कुर्मनवो नृपः ॥ इति यजुर्वेदे । . . . संहितायाः पञ्चाधिकरणाभिमानित्वं प्राणादिरूपस्य वायोरपि भवति । पृथिव्यन्तरिक्षमित्युक्त . . . । अतः उपक्रमोपसंहारयो स्त्वमेव प्रत्यक्षंब्रह्मवदिष्यामि, त्वामेव प्रत्यक्षं ब्रह्मावादिषु(षं) युज्यते ।

(f) रुक्मिणीशविजयः by वादिराजः

RUKMIṆĪŚAVIJAYAḤ by Vādirāja.

Foll. 67a—80b. Extent, 280 Granthas. Printed.

Same work as that described under D. No. 11716.

Contains Sargas 13, 15, 16 only complete.

(g) प्रणवदर्पणखण्डनम् by लक्ष्मीनृसिंह:

PRAṆAVADARPAṆAKHAṆḌANAM by Lakṣminṛsiṁha, son of Kṛṣṇa.

Foll. 81a—86b. Extent, 140 Granthas.

Similar to the work described under D. No. 4798.

Beginning :

संभाव्यते बुधजनै रघुना(पि)योऽयं
सन्तो . . . . सज्जनपरो महिताऽन्ववायः ।
संसेवितः सुकृतिभिः परमादरेण
वंशेऽत्र सन्मणिरमूत्किल रामचन्द्रः ॥
तस्माद्गुणै रनवमो नवमः प्रकृत्या
यस्त्वादुमङ्गलजः कृष्णसुधीः प्रसिद्धः ।
लक्ष्मीविनिह्म इति तस्य सुतोगुरुणां
शिक्षावशात्किमपि कौतुक मातनोति ॥
प्रणवोच्चारणं सूत्रेष्वा . . . . दूषयन् ।
तदलप्रकर्ता वक्ष्ये यथामति यथास्थिति ॥
तत्रेदं सौरपुरीयं दूषणम् ।
प्रणवोच्चारस्योक्तावे . . . सन्तःस्थता श्रुतौ ।
उपक्रमोपसंहारमात्रे चैतत् व्यवस्थितम् ॥
प्रतिवाक्यं प्रतिपदं न तद्दृष्टं न सम्मतम् ।
प्रतिसूत्रं तदिष्टं ते प्रमाणं तत्र दुर्लभम् ॥
तल्लाभेऽपि न तत्सूत्रावयवत्वोपपादकम् ॥

अ . . . . पप्रतियोग्यर्थानुपस्थापकता यतः । इति तस्येदं प्रति-
वचनम् ।

End :

तदेवं गारुडवचः प्रमाणं भारसंग्रहे ।
आग्रहात्केवलं चैतत्सुस्वरं विस्मरन्ति ते ।
प्रणवोच्चारणं सूत्रेष्वा सेव . . . . तिच ।
श्रौतं पौराणिकं बाधरहितं चेति मन्महे ।
अपि स्वकीयवचनपीयूषै रेव तुष्यताम् ॥
सतामेव भवेत्प्रीत्यै . . . . .मामिका ।
अनेन लेखनेन श्रीमध्वेशः प्रीयताम् ॥

(*h*) जयतीर्थविजयः by व्यासतीर्थः

JAYATĪRTHAVIJAYAḤ by Vyāsatīrtha.

Foll. 87*a*—92*b*. Extent, 110 Granthas.

Similiar to the work described under R. No. 858 (*a*).

Complete.

Beginning :

नत्वा विष्णुं तथा मध्वं जयतीर्थगुरूनपि ।
वक्ष्ये श्रीमज्जयार्याणां स्तोत्रं सर्वसमृद्धिदम् ॥
श्रीमानिन्द्र स्सुधीमान् . . . . . . प्रार्थ्यमानं सुशास्त्रं
श्रोता त्वेकाग्रबुद्ध्या ह्यपतनु रभूच्छ्रीमदानन्दतीर्थात् ।
. . . त्वा तच्छास्त्रतीरं प्रतिदिन मशृणो द्वाच्यमानं सुशास्त्रं
प्रान्तेऽसौ सूपविश्यद् द्विजगणसहितो भक्तिभारं दधानः ॥
रोषादीना मगम्यं तव मुखजनितं शास्त्र मालोच्य केवा
व्याख्यास्यन्तीति पृष्टस्स . . . समुनिरवदत्सुस्मितास्तीर्थशिष्यैः ।
व्याख्यास्यत्येष गोच . . . तकुपिततराः शिष्यका . . पुरेनं
गोराजोऽसावयोग्यः प्रवचनसमये सर्पदष्टो भूयेत ॥
इत्थं शप्तं स्वशिष्यैः ह्यपमतनु मसौ श्रीपतिः क्षेमदोऽयं
दत्वा शापस्य मोक्षं प्रवचनविषये द्वादशस्तोत्रपाठम् ।
दृष्टान्तं तस्य वक्त्रप्रकपरनिधांशो यतीन्द्रोऽनिवाग्मी-
मध्वो मन्यार्थवाक्यो मधुमथनपदं मानसाचिन्तयानः ॥

End :

चित्रं श्रीमज्जयार्यैः कृतमतिविशदं विक्रमं को न वक्ता
किंतु श्रुत्यर्थ मल्पं गुरुभिरनुदितं वर्णितं वर्णितं मे ।
तेन श्रीमध्वनाथो यदुकुलतिलको माधवो मानसिद्धौ
भूयात्प्रीतिस्समस्ता अपि गुरवः प्रीतियुक्ता भवन्तु ॥

Colophon :

इति श्रीमज्जयतीर्थपूज्यपादशिष्येण व्यासतीर्थयतिना विरचितो जयतीर्थविजयस्संपूर्णः ।

(i) न्यायसिद्धान्तमञ्जरी by जानकीनाथः
NYĀYASIDDHĀNTAMAÑJARĪ by Jānakīnātha.

Foll. 93a—121. Extent, 580. Printed.
Same work as that described under D. No. 4215.
Complete.

R. No. 5889

Palm leaf. 16 × 1½ inches. Foll. 78. Lines, 7 in a page. Nandināgarī. Good
Purchased from Śrī P. Veṅkaṭaramaṇācār, Triplicane, Madras.

(a) पुरुषसूक्तव्याख्या by जयतीर्थः
PURUṢASŪKTAVYĀKHYĀ by Jayatīrtha.

Foll. 1a—2a. 2b is left blank. Extent, 45 Granthas.
This is a commentary on the Puruṣasūkta by Jayatīrtha.
Incomplete.

Beginning :

पुरुषसूक्तव्याख्यानं जयतीर्थीयम् ।

सहस्रशीर्षापुरुषः । सहस्राक्षः सहस्रपात् । सभूमिं विश्वतो वृत्वा । अत्यतिष्ठद्दशाङ्गुलम् । सहस्रशब्दोऽनन्तवाची, पुरुषः पूर्णषड्गुणः, हरिः सहस्रशीर्षोऽनन्तशिराः ।

End :

बर्हिषि- आज्ये हवींषि प्रोक्षन् हविरादि पुरुषेणोक्षितवन्तः । उक्ष सेचने । तेन प्रोक्षितेन हविरादिना साध्या देवाः येच ऋषयः ते पुरुषं अयजन्त - अपूजयन् ।

(b) ब्रह्मसूत्रसङ्गत्यर्थप्रकाशः by पद्मनाभः
BRAHMASŪTRA SAṄGATYARTHA PRAKĀŚAḤ by Padmanābha.

Foll. 3a—10b. Extent, 200 Granthas.
In this work, Padmanābha deals with the mutual relation of the Brahma sūtras.

Contains Janmādhikaraṇa complete.

Beginning :

कृष्णरामौ संप्रणम्य रघुनाथगुरुनपि ।
व्यासोपक्रमसूत्राणां सङ्गत्यर्थौ वदाम्यहम् ॥
टीकासुधाचन्द्रिकासु प्रोक्तार्थः संप्रकाश्यते ।
पद्मनाभेन विदुषा कृपां कुर्वन्तु सूरयः ।

वैवस्वतमन्वन्तरेऽष्टाविंशतितमे द्वापरेयुगे नष्टधर्मज्ञानलोककृपालुभिः ब्रह्मरुद्रेन्द्रादिभिरर्थितो भगवान्नारायणः सम्यग्ज्ञानद्वारा मोक्षो भवेदिति कृपालु र्व्यासत्वेनावततार । अथ वेदार्थमविदुषां सज्जनानां सम्यग्ज्ञानजननाय वेदेतिकर्तव्यतारूपब्रह्मसूत्राण्यचीक्लृपत् । तत्रादौ ब्रह्मजिज्ञासेति जिज्ञासाकर्तव्यताविधायकंसूत्रम् ।

End :

जगज्जन्मादिकर्तृस्वरूपलक्षणस्य विवक्षितत्वात् । रमा व्याव . . . हारावर्णजीवस्वरूपाणां नित्यत्वेनोत्पत्त्यभावेपि पराधीनविशेषावाप्तिरूपोत्पत्ते र्वे . . . करणोक्तन्यायासम्भवादितिसंक्षेपः ।

Colophon :

॥ जन्माधिकरणं संपूर्णम् ॥

(c) ब्रह्मसूत्रभाष्यार्थमञ्जरी by वेदगर्भ नारायणः

BRAHMASŪTRABHĀṢYĀRTHAMAÑJARĪ by Vedagarbha Nārāyaṇa.

Foll. 12a—78b. Foll. 11 is left blank. Extent, 1,876 Granthas.

In this work, Vedagarbha Nārāyaṇa gives in brief, the interpretation of the Madhva School of the Brahma Sūtras.

Contains Pādas 1 and 2 in the first Adhyāya.

Beginning :

लक्ष्मीनारायणं व्यासं पूर्णप्रज्ञं च भारतीम् ।
टीकाचार्यं व्यासतीर्थं रघुनाथगुरुं भजे ।
टीकाचार्योक्तमार्गेण स्वगुरूक्तानुसारतः ।
क्रियते तत्प्रसादेन सूत्रभाष्यार्थमञ्जरी ।
स्ववाक्यानि प्रमाणानि भाष्यगान्यखिलान्यपि ।
सूत्रार्थत्वेन नीयन्ते योगादिबलतो मया ।
टीकोक्तार्थानुवादेन तदनुक्तार्थपूर्वकम् ॥

* * * *

॥ जन्माद्यस्य यतः ॥ ओं ॥ अत्र तद्विजिज्ञासस्वेति जिज्ञास्यत्वेन श्रुत्युक्तस्य ब्रह्मणो विष्णुत्वं समर्थ्यते । पूर्वपक्षस्य सूचनाप्रकारस्तु—

End :

पूर्णषड्गुण इत्यादिना वाक्येन श्रुतयः आमनन्ति प्रतिपादयन्ति, इत्यन्वयः । अतोऽयं वैश्वानरोविष्णु रेवेति तस्यैव सर्वगतत्वमिति सिद्धम् ।

Colophon :

इतिश्रीमद्ब्रह्मसूत्रभाष्यार्थमञ्जर्यां वेदगर्भनारायणेन विरचितायां प्रथमाध्यायस्य द्वितीयः पादः ॥

R. No. **5890**

Palm leaf. 17 × 1¼ inches. Foll. 117. Lines, 9 in a page. Nandināgari. Extent, 8,000. Much injured and disorder.

Purchased in 1936–37 from Śrī P. Veṅkaṭaramaṇācār, Triplicane, Madras.

विष्णुतत्त्वनिर्णयटीकाव्याख्या

(विषमपदवाक्यार्थविवृतिः) by केशवः

VIṢṆUTATTVANIRṆAYAṬĪKAVYĀKHYĀ (VIṢAMAPADAVĀKYĀRTHAVIVṚTIḤ) by Keśava.

This is a commentary on the Viṣṇutattvanirṇayaṭīkā of Jayatīrtha.

This manuscript is said to have been transcribed by Śrīnivāsa, elder son of Kūrmācārya, on Tuesday, the 10th day of the Śrāvaṇa month in the year Pramādi.

Contains Paricchedas 1 to 3 but incomplete.

Beginning :

..... अनन्तगुण .. . प्रधानलक्षणं पितरमित्यादिना .... तत्संभावकजन्माद्यस्य यत इति द्वितीयसूत्रोक्तजगज्जन्मादिकारणत्वरूप लक्षणं .... प्रणामस्येव गुरुप्रणामस्याप्याभिमतसाधनतया यस्य देव इत्यादिप्रमाणसिद्धत्वा देवताप्रणामानन्तरं

गुरू निन्दुत्वेन रूपयन् प्रार्थयते लसत्विति । साक्षाद्गुरुप्रणतिपुरस्सरं शिष्यमन . ... चिकीर्षितं निर्दिशति ...... तच्च गुरुत्वोपपादकं विशेषणम् । अत्रपदार्थज्ञानोपायभूतं पद्ये शब्दार्थोऽनेनेति कृत्वा व्याख्याकरणं पदवाक्यार्थज्ञानोपायन्यायसमर्पक ...... मीमांसाशास्त्रं शक्यं,

Colophon :

इती श्रीमत्पदवाक्यप्रमाणविदामग्रेसराणां सकलविद्वज्जनचूडामणीनां श्रीमद्विद्याधशिपूज्यपादानां निजशिष्येणकेशवेन विरचितायां गुरुराज-मतानुवर्तिन्यां तत्त्वनिर्णयगतटीकागतविषमपदवाक्यर्थविवृतौ प्रथमः परिच्छेदः समाप्तः ॥

End :

विशिष्टेति । अतएव सुरा अधिकारिणोऽत्रेत्युक्त मुपपन्नामिति । सकलमकलङ्कम् ॥

यद्विद्याधीशगुरोः शुश्रूषान्या नरोचते यस्मात् ।
अत्लेषा भक्ति युता श्रीविद्याधीशपादयोः सेवा ॥

Colophon :

इति श्रीमत्पदवाक्यप्रमाणविदामग्रेसराणां सकलविद्वज्जनचूडामणीनां श्रीमद्विद्याधीशापूज्यपादानां निजशिष्येण केशवेन विरचितायां गुरुराजमतानुवर्तिन्यां तत्त्वनिर्णयटीकागतविषमपदवाक्यर्थविवृतौ तृतीयः परिच्छेदः समाप्तः ॥

R. No. **5891**

Palm leaf. 14¾ × 1¼ inches. Foll. 45. Lines, 6 in a page. Nandināgarī. Extent, 1,000 Granthas. Injured.

Purchased in 1936–37 from Śrī P. Veṅkaṭaramaṇācār, Triplicane, Madras.

सन्ध्यावन्दनमन्त्रभाष्यम्

SANDHYĀVANDANAMANTRABHĀṢYAM.

Foll. 1*a*—42*b*. 43*a*—45*a* contains 19 stanzas in the first sarga of Śiśupālavadhakāvya. 45*b* is left blank. Similar to the work described under D. No. 2881.

Complete.

Beginning :

लक्ष्मीलक्ष्मीशपादाभ्या मियमस्तु नमस्कृतिः ।
यया निखिलभाग्यानि भवेयु र्भजतां हरिम् ।
श्रुतिस्मृत्युदितं कृत्यं यदाराधनसाधनम् ।
तद्विधायकमन्त्राणां वृत्तिं वक्ष्ये यथाक्रमम् ॥
यावन्तोऽस्यां विकर्मस्थाः पृथिव्यां बालिशाद्विजाः ॥
तेषां पावित्र्यसिद्ध्यर्थं सन्ध्या सृष्टा स्वयंभुवा ॥

व्यासः—

उपास्तिः सन्धौ सूर्यस्य निशाया दिवसस्य च ।
तामेव ताभ्यां सन्ध्यां प्रवदन्ति महर्षयः ॥

* * * *

Colophon :

इति प्रातस्सन्ध्याप्रकरणं संपूर्णम् ।

End :

तदर्थमिद मभिमन्त्रितजलं स्वाहा मदीये वक्त्राग्नौ सुहुहुतमस्तु । अवशिष्टं कर्मजातं प्रागुक्तं बोध्यम् ।

R. No. 5892

Palm leaf. 18½ × 1¼ inches. Foll. 69. Lines, 9 in a page. Nandināgarī. Much injured. Extent, 2,400 Granthas. Printed.

Purchased in 1936–37 from Śrī P. Veṅkataramaṇācār, Triplicane, Madras.

ऋग्भाष्यटीका by जयतीर्थः

ṚGBHĀṢYAṬĪKĀ by Jayatīrtha.

Same work as that described under D. No. 16909.

Complete.

R. No. 5893

Palm leaf. 15¾ × 1½ inches. Foll. 156. Lines, 6 in a page. Nandināgarī. Good. Extent, 3,800 Granthas.

Purchased in 1936–37 from Śrī P. Veṅkaṭaramaṇācār, Triplicane, Madras.

तन्त्रसारटिप्पणी — तन्त्रसारार्थसंग्रहः

TANTRASĀRAṬIPPAṆI—TANTRASĀRĀRTHASAṄGRAHAḤ.

Similar to the work described under R. No. 863.

Incomplete.

Beginning :

लक्ष्मीनारायणं पूर्णज्ञानानन्दादिसद्गुणम् ।
मन्त्रवर्णाभिधेयं च वन्दे ब्रह्मादिवन्दितम् ॥
सत्यनिध्याख्य यतिराट् छलाग्निहरी गुरू ।
मन्त्रविद्योपदेष्टारौ वन्देऽभिमतसिद्धये ॥

बहुज्ञबहुटीकाभ्यो बुद्ध्वारे हार्थमञ्जसा ।
मध्वोक्ततन्त्रसारार्थसंग्रहः क्रियते मया ॥

अथ श्रीविष्णुप्रीत्यर्थं सर्वै र्भगवत्प्रतिपादकमन्त्रजपतत्पूजादे र्ज्ञातव्यत्वा त्कर्तव्यत्वाच्च तस्य चाल्पायुष्यप्रज्ञादिभिरतिविस्तृत विष्णूदित तन्त्रसारोक्त-प्रकारेण ज्ञातुं कर्तुं च सर्वथाऽशक्यत्वात्.

End :

केन प्रकारेणोपासित इत्यत उक्तम् । आनन्देति । आनन्दश्चि त्ज्ञानम् । स . . . त्वं निर्दुष्टत्वमात्मत्वं च ग्राह्यं तदर्थः स्वामित्व-मिति । एते गुणा एव पूर्वा येषां गुणानां तैर्गुणैः क्रमेण अधिकै र्बहुभिस्सहितत्वेन . . ध्यात इत्यर्थः । मनुष्योत्तमैः-सर्वदानन्द आत्मेति चतुर्भिर्गु . . .

R. No. 5894

Palm leaf. 15¾ × 1¼ inches. Foll. 154. Lines, 6 in a page. Nandināgarī. Injured.

Purchased in 1936–37 from Śrī P. Veṅkaṭaramaṇācār, Triplicane, Madras.

(a) गोत्रप्रवरखण्डः by आपस्तम्बः

GOTRAPRAVARAKHAṆḌAḤ by Āpastamba.

Foll. 5a—7b. Foll. 1a—4a contains Smṛtisaṅgrahānukramaṇikā and 4b is left blank. Extent, 85 Granthas.

Same work as that described under D. No. 2912.

Complete.

(b) गोत्रप्रवरनिर्णयः by माधवाचार्यः

GOTRAPRAVARANIRṆAYAḤ by Mādhavācārya.

Foll. 8a—26b. Extent, 540 Granthas.

Same work as that described under D. No. 2923, but with a different colophon as given below.

Complete.

Colophon :

इति श्रीताम्रपर्णिश्रीनिवासाचार्यरचिते गोत्रप्रवरनिर्णये दशमं प्रकरणं समाप्तम् ।

(c) स्मृतिसारसंग्रहः by श्रीनिवासाचार्यः
SMṚTISĀRAHSAṄGRAHAḤ by Śrinivācārya.

Foll. 26b—137a. Extent, 3,300 Granthas.

Same work as that described under R. No. 1434 (c) but with colophon and end as given below.

Complete.

End :

द्रष्टव्य मधिकं कृष्णाचार्यस्मृतौ ॥

Colophon :

इति विठ्ठलाचार्यतनुजेन तीर्थायिचरणसेविना श्रीश्रीनिवासेन कृतः स्मृतिसारसंग्रहः समाप्तः ।

(d) स्मृतिसंग्रहः by कृष्णाचार्यः
SMṚTISAṄGRAHAḤ by Kṛṣṇācārya.

Foll. 137a—154b. Extent, 580 Granthas.

In this work, Kṛṣṇācārya gives the views of the various Dharma Śāstras on certain points like Upākarmotsarjananirūpaṇa and others.

Incomplete.

Beginning :

अथोपाकरणकालः सम्यङ्निरूप्यते । तत्रयाज्ञवल्क्यः,

अध्यायानामुपाकर्म श्रावण्यां श्रवणेऽपिवा

हस्तेनौषधिभावेवा पञ्चम्यां श्रावणस्यतु ॥ इति ।

Colophon :

इति श्रीकृष्णाचार्यकृतस्मृतिसंग्रहे उपाकर्मोत्सर्जननिरूपणं समाप्तम् ।

End :

विहितत्यागिनां चैव आशौचं सर्वदैव भवतीति तत्त्यागिनांभिक्षा गुरुकुलवासदेशाध्ययनादि हीनानामित्यर्थः । इति स्मृतिकौस्तुभे ।

R. No. 5895

Palm leaf. 18¼ × 1½ inches. Foll. 48. Lines, 7 in a page. Nandināgari. Injured. Extent 1,130 Granthas. Printed.

Purchased in 1936-37 from P. Veṅkaṭaramaṇācāryar, Triplicane, Madras.

विष्णुतत्त्वनिर्णयटीका by जयतीर्थः

VIṢṆUTATTVANIRṆAYAṬĪKĀ by Jayatīrtha.

Foll. 1a—48a. 48b is left blank.
Same work as that described under D. No. 4843.

R. No. 5896

Palm leaf. 16¾ × 1½ inches. Foll. 43. Lines, 7 in a page. Nandināgarī. Good. Old.

Purchased in 1936-37 from Śrī P. Veṅkaṭaramaṇācāryar, Triplicane, Madras.

(a) न्यायामृतव्याख्या - प्रकाशः by श्रीनिवासः

NYĀYĀMṚTAVYĀKHYĀ—PRAKĀŚAḤ by Śrīnivāsa.

Foll. 1a—27b. Foll. 28 is left blank. Extent, 700 Granthas, Printed.
Same work as that described under R. No. 855.
Incomplete.

(b) अभिनयदर्पणम् by नन्दिकेश्वरः

ABHINAYADARPAṆAM by Nandikeśvara.

Foll. 29a—34a. Foll. 34b is left blank. Extent, 140 Granthas.

Same work as that described under D. No. 12980, but the addition of one stanza at the end as given below :—
Complete.

शृङ्गारं क्षितिनन्दनाविहरणे वीरं धनुर्भञ्जने
कारुण्यं बलिभोजनेऽद्भुतरसं बाणाम्बुधौस्थापने ।
हास्यं शूर्पणखामुखे भय मघे बीभत्समन्यामुखे
रौद्रं रावणमर्दने मुनिजने शान्तं वपुः पातु माम् ॥

(c) न्यायामृतम् by व्यासयतिः

NYĀYĀMṚTAM by Vyāsayati.

Foll. 35a—43a. Foll. 43b is left blank. Extent, 220 Granthas.
Same work as that described under R. No. 871.
Incomplete.

R. No. 5897

Palm leaf. 15¾ × 1½ inches. Foll. 64. Lines, 7 in a page. Nandināgarī. Slightly injured.

Purchased in 1936-37 from Śrī P. Veṅkaṭaramaṇācār of Triplicane, Madras.

(a) सत्तत्त्वरत्नमालाव्याख्या

SATTATTVARATNAMĀLĀVYĀKHYĀ.

Foll. 1a—48b. Extent, 1,300 Granthas.
Same work as that described under D. No. 4845.
Incomplete.

(b) परिमलटिप्पणम्

PARIMALAṬIPPAṆAM.

Foll. 49—62a. Foll. 62b is left blank. Extent, 324 Granthas.

This is a brief commentary on the Nyāyasudhāvyākyā, namely, Parimala of Rāghavendrayati, which work has been described under D. No. 4821.

Incomplete.

Beginning :

परिमलटिप्पणीमातृकायां 48 पत्रमारभ्यालिख्यते । नियतेति । सत्यस्यापि ज्ञानेन निवृत्तौ बाधकाभावेने त्युक्तमिति भावेन बाधक माशङ्कते सत्यस्यापीति ।

End :

विवृतमेत न्यायामृते सत्तात्रैविध्यभङ्गे । शङ्कते नामुख्यमिति । अमुख्यं सदित्यनुवादः । वा सतु नापि सदितिकोटिद्वयनिषेधः । अन्यारादितरर्ते-दिक्शब्दाञ्चूत्तरपदाजाहियुक्त इति पञ्चमीविधिसूत्रेऽन्यइत्यर्थग्रहणोक्तिः । सदसद्भ्यामिति वाक्यमित्यत आह सम्बन्धमात्रे षष्ठीति ।

(c) योगविषयः

YOGAVIṢAYAḤ.

Foll. 63a—64b. Extent, 50 Granthas.
A treatise on yoga.
Incomplete.

Beginning :

त्वक्चर्ममांसरुधिरमेदोमाज्जस्थिनामकाः ।
धातवस्सप्त सन्त्यस्मिन्स्थूलेदेहे क्रमेण हि ॥
हिङ्कारनामा प्रद्युम्नो देहेस्थे रोमणि स्थितः ।
प्रस्थावाख्योऽनिरुद्धस्तु त्वक्स्यस्सङ्कर्षणो हरिः ॥

End :

आदा वैक्यं समायाति तैजसेन शरीरिणा ।
स्वमावस्था समुद्दिष्टा जीवादृष्टानुसारतः ॥
रसनामयवस्तूनि सृजत्यादाय तैजसः ।
जीवप्रकाश मादाय तैज . . . . . . ॥

R. No. 5898

Palm leaf. 14¼ × 1½ inches. Foll. 112. Lines, 6 in a page. Nandināgari. Good.

Purchased in 1936–37 from Śrī P. Veṅkaṭaramaṇācār, Triplicane, Madras.

(*a*) मायावादखण्डनपञ्चिकाव्याख्या by श्रीनिवासः

MĀYĀVĀDAKHAṆḌANAPAÑCIKĀVYĀKHYĀ by Śrīnivāsa.

Foll. 1*a*—13*a*. Extent, 250 Granthas. Printed.
Same work as that described under D. No. 15718.
Complete.

(*b*) उपाधिखण्डनटीकाविवृतिः by श्रीनिवासः

UPĀDHIKHAṆḌANAṬĪKĀVIVṚTIḤ by Śrīnivāsa.

Foll. 13*a*—49*b*. Extent, 1,140 Granthas. Printed.
Same work as that described under D. No. 17290.
Complete.

The transcription having been completed on Monday, the 3rd day in the dark fortnight of the month of Āśvayuja in the year Pramodūta.

(*c*) प्रपञ्चमिथ्यात्वानुमानखण्डनपञ्चिकाव्याख्या by श्रीनिवासः

PRAPAÑCAMITHYĀTVĀNUMĀNAKHAṆḌANAṬĪKĀVYĀKHYĀ by Śrīnivāsa.

Foll. 50*a*—112*b*. Extent, 1,764 Granthas. Printed.

The manuscript is said to have been copied by Narasiṁha on Monday, the 8th day in the dark fortnight of the month Kārtikai in the year Pramodūtā.

Same work as that described under D. No. 17048 wherein see for beginning.

Complete.

End :

जयति=उत्कृष्टो वर्तते । इत्यशेष मतिमङ्गलम् ।
यादवाचार्यहृत्पद्मगतश्रीमध्वहृद्गतः ।
प्रीयता मनया ग्रन्थकृत्या व्यासो गुणाकरः ॥
श्रीमध्वकृतसिद्धान्तं योऽस्थापयत् स्नेहतो मयि ॥
तं वन्दे यादवाचार्यगुरुं शिष्यकृपानिधिम् ॥

Colophon :

इति श्रीमद्यदुपत्याचार्यपूज्यपादाराधकेन श्रीनिवासेन विरचिता प्रपञ्चमिथ्यात्वानुमानखण्डनपञ्चिकाव्याख्या समाप्ता ॥

R. No. **5899**

Palm leaf. 15¾ × 1½ inches. Foll. 80. Lines, 7 in a page. Nandināgarī. Good.

Purchased in 1936-37 from P. Veṅkaṭaramaṇācāryar, Triplicane, Madras.

(*a*) तत्त्वचिन्तामणिदीधितिप्रकाशिका by गदाधरः

TATTVACINTĀMAṆIDĪDHITIPRAKĀŚIKĀ by Gadādhara.

Foll. 1*a*—72*b*. Extent, 1,728 Granthas. Printed.

Same work as that described under D. No. 4050.

Contains Savyabhicāra incomplete.

(*b*) ईशावास्योपनिषद्भाष्यटीका by जयतीर्थः

ĪŚĀVĀSYOPANIṢADBHĀṢYAṬĪKĀ by Jayatīrtha.

Foll. 73*a*—80*a*. Foll. 80*b* is left blank. Extent, 200 Granthas. Printed.

Same work as that described under R. No. 493.

Incomplete.

R. No. **5900**

Palm leaf. 17¾ × 1¼ inches. Foll. 78. Lines, 7 in a page. Nandināgarī. Injured. Extent, 2,340 Granthas.

Purchased in 1936-37 from P. Veṅkaṭaramaṇācāryar, Triplicane, Madras.

विष्णुतत्त्वनिर्णयटीकाव्याख्या by श्रीनिवासः

VIṢṆUTATTVANIRṆAYAṬĪKĀVYĀKHYĀ by Śrīnivāsa.

Foll. 1*a*—78*b*.

Similar to the work described under R. No. 5890.

Incomplete.

Beginning :

श्रीरामं हनुमत्सेव्यं श्रीकृष्णं भीमसेवितम् ।
श्रीव्यासं मध्वसंसेव्यं तमस्ताभीष्टदं भजे ॥

श्रीमदानन्दतीर्थार्यचरणा वाश्रयेऽनिशम् ।
रुद्रादिसर्वविबुधैः संसेव्या विष्टदौ सताम् ॥

श्रुतिक्षीराब्धिमा मथ्य धीमन्दरमहीभृता ।
प्राप्ता न्यायसुधा येन तं जयेन्द्रमहं भजे ॥

अधैतत्कृपया श्रीनिवासेन विदुषा हरेः ।
तत्त्वनिर्णयटीकाया व्याख्यानं क्रियते मया ॥

सर्वज्ञकल्पाः टीकाकाराः जयतीर्थ श्रीमच्चरणाः स्वचिकीर्षितग्रन्थस्य निर्विघ्नेन परिसमाप्त्यर्थं स्वेष्टदेवतानमनरूपं मङ्गलंकृत्वा शिष्यशिक्षार्थं ग्रन्थाद्दा वुपनिबध्नाति विश्वस्येति ।

End :

कार्यान्वयनियमेति । कार्यान्वितप्रवृत्त्युत्पत्तिरिति परोक्तकार्यान्वयनियम-निराकरणार्थंएव .... शब्दोनतुकार्यान्वितव्युत्पत्तिनिराकरणार्थं इत्यर्थः । कार्यान्वित एवार्थे सर्वशब्दानांव्युत्पत्तिदर्शनादित्येव वक्तव्यं ननु गृहीतेऽनुपादानादिति । असङ्गतत्वादतो गृहतिपदम् ।

R. No. 5901

Palm leaf. 15¼ × 1½ inches. Foll. 98. Lines, 7 in a page. Injured. Extent, 3,000 Granthas.

Purchased in 1936–37 from Śrī Veṅkaṭaramaṇācāryar, Triplicane, Madras.

विष्णुतत्त्वनिर्णयटीकाव्याख्या—श्रीनिवासप्रणीता

VIṢṆUTATTVANIRṆAYAṬĪKĀVYĀKHYĀ by Śrīnivāsa.

Same work as that described under R. No. 5900.

Incomplete.

R. No. 5902

Palm leaf. 16¾ × 1¼ inches. Foll. 80. Lines, 7 in a page. Nandināgari. Good.

Purchased in 1936–37 from Śrī P. Veṅkataramaṇācāryar, Triplicane, Madras.

(*a*) तत्त्वोद्द्योतटीकाविवृतिः—(भावदीपः) by राघवेन्द्रयतिः

TATVODDYOTAṬIKĀVIVṚTIḤ (BHĀVADĪPAḤ) by Rāghavendrayati.

Foll. 1*a*—29*a*. Foll. 29*b* is left blank. Extent, 700 granthas. Printed.

Same work as that described under R. No. 14.

Complete.

(*b*) तत्त्वोद्द्योतपञ्चिकाव्याख्या by वेदेशिभिक्षुः

TATTVODDYOTAPAÑCIKĀVYĀKHYĀ by Vedeśibhikṣu.

Foll. 30*a*—80*a*. Foll. 80*b* is left blank. Extent, 1,200 Granthas. Printed.

Same work as that described under R. No. 3928 (*d*).

Complete.

R. No. 5903

Palm leaf. 15¾ × 1¼ inches. Foll. 101. Lines, 9 in a page. Nandināgari. Good.

Purchased in 1936–37 from Śrī P. Veṅkaṭaramaṇācāryar, Triplicane, Madras.

(*a*) तर्कताण्डवम् by व्यासतीर्थः

TARKATĀṆḌAVAM by Vyāsatīrtha.

Foll. 1*a*—82*a*. Foll. 82*b* is left blank. Extent, 3,000 Granthas.

This work deals with the Nyāya principles interpreted in the light of the Dvaita School.

Contains Paricchedas 2 and 3 complete, but wants beginning in 2nd Pariccheda.

Beginning :

अस्य शब्दस्य वृत्तिस्त्रेधा । अभिधा, लक्षणा, गौणीचेति ।
तदुक्तमनुव्याख्याने—

तस्मात्परममुख्यत्वं विष्णावन्यत्रमुख्यता ।
उपलक्षणा च गौणी च तिस्रः शब्दस्य वृत्तयः ॥ इति ॥

तत्राद्यामुख्यवृत्तिरित्युच्यते । द्वितीयतृतीयेत्वमुख्यवृत्ती इति ।

Colophon :

इति श्रीमद्ब्रह्मण्यतीर्थपूज्यपादानां शिष्येण व्यासयतिना विरचिते तर्कताण्डवे द्वितीयः परिच्छेदः ।

End :

तदेतदभिप्रेत्योक्तं प्रमाणलक्षणे असिद्धिरव्याप्तिरिति हेतुर्विरोध इति । सामान्येन परोक्तहेत्वाभासभङ्गः ।

Colophon :

इति श्रीब्रह्मण्यतीर्थपूज्यपादानां शिष्येण व्यासयतिना विरचिते तर्कताण्डवे तृतीयः परिच्छेदः ।

अत्र पुस्तके शब्दपरिच्छेदेरूढयादिवृत्तित्रयस्य लक्षणमारभ्य समग्रं वर्तते । पत्रसङ्ख्या 82 पूर्वभागः पुस्तकान्तरे ।

(a) वादावलिः by जयतीर्थः

VĀDĀVALIḤ by Jayatīrtha.

Foll. 83*a*—95*a*. Foll. 95*b* is left blank. Extent, 450 Granthas. Printed.

Same work as that described under D. No. 4839.

Incomplete.

(b) प्रणवदर्पणखण्डनम् by विजयीन्द्रतीर्थः

PRAṆAVADARPAṆAKHAṆḌANAM by Vijayīndratīrtha.

Foll. 96*a*—101*b*. Extent, 150 Granthas.

Same work as that described under D. No. 4798.

Incomplete.

R. No. 5904

Palm leaf. 15¼ × 1¼ inches. Foll. 89. Lines, 6 in a page. Nandināgarī. Good. Extent, 2,136 Granthas. Printed.

Purchased in 1936–37 from P. Veṅkaṭaramaṇācāryar, Triplicane, Madras.

मुक्तावलीव्याख्यानम् by महादेवः
प्रकाशः
MUKTĀVALĪVYĀKHYĀNAM PRAKĀŚAḤ by Mahādeva.

This work is also called Dinakarabhattīya.

Same work as that described under D. No. 3955.

Contains Pratyakṣa, Anumāna and Upamāna, incomplete.

R. No. 5905

Palm leaf. 10¼ × 2¼ inches. Foll. 9. Lines, 12 in a page. Nandināgarī. Good. Extent, 400 Granthas. Printed.

Purchased in 1936-37 from Śrī P. Veṅkaṭaramaṇācāryar, Triplicane, Madras.

गीताभाष्यव्याख्या by जयतीर्थः
(प्रमेयदीपिका)
GĪTĀBHĀṢYAVYĀKHYĀ (PRAMEYADĪPIKĀ) by Jayatīrtha.

Same work as that described under R. No. 5811 wherein see for beginning and end.

Contains Adhyayas 9 and 10 incomplete.

Beginning :

पल मित्यस्य परिहारो नहश्यते । अत आह । तेषामिति अनर्थत्वप्रदर्शनाय व्याचष्टे वृथेति । संपदादिप्राप्तिदर्शनात्कथमित्यत आह भगवदिति । यज्ञादिकर्मणां साफल्यदर्शनात्कथं मोघकर्माण इत्यत आह यज्ञादीति । ज्ञानं तत्त्वविषयं तेषां नास्त्यव.

Colophon :

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितस्य श्रीमद्भगवद्गीताभाष्यस्य टीकायां जयतीर्थमुनिविरचितायां प्रमेयदीपिकायां नवमोऽध्यायः ।

Colophon :

इति श्रीमदानन्दतीर्थभगवत्पादविरचितस्यगीताभाष्यस्य जयतीर्थमुनि विरचितायां प्रमेयदीपिकायां दशमोऽध्यायः ।

End :

आद्यं दूषयति अतिप्रसङ्गस्त्विति । अविशेषमाश्रित्यह्ययमतिप्रसङ्गः । नचासावस्ति। निर्दोषानन्तगुणत्वे हरेः श्रुतीनां महातात्पर्यो दुस्तावस्तद्विरोधात्। परिमाणद्वयस्तु तदविरोधात् ।

R. No 5906

Palm leaf. 18 × 1¼ inches. Foll. 38. Lines, 7 in a page. Nandināgarī. Injured. Extent, 1,370 Granthas.

Purchased in 1936–37 from Śrī P. Veṅkataramaṇācāryar, Triplicane, Madras.

ब्रह्मसूत्रभाष्यम्

BRAHMASŪTRABHĀṢYAM.

A commentary on the Brahmasūtras, in the light of the Dvaita School of Indian Philosophy.

Incomplete.

Beginning :

नान्त्यदेत्यवंरूपतदवच्छेदरहिताच । न तृतीयः, ध्वंसेऽतिव्याप्तेः । ननु ध्वंसोऽपि ध्वंसप्रतियोगी । प्रतियोग्यनुन्मज्जनं तु प्रागभावनिवृत्तिरूपस्य घटस्य निवृत्तावपि प्रागभावानुन्मज्जन वा . . . . . . क्षमितिचेत्तन्न । एवं सति मोक्षेऽपि आत्मान्यस्य कस्यचित् ध्वंसस्य वक्तव्यतया लाघवार्थं माद्यध्वंसनित्यताया एव युक्तत्वात् ।

* * * *

परमते ब्रह्मणोज्ञानत्वानन्दत्वाद्वितीयत्वनित्यत्वसाक्षित्वभङ्गः । यच्चेदमुच्यते । ब्रह्मजगदुपादानत्वेसति कर्तृ . . . निमित्तोपादानं जगदिति

Colophon :

॥ ब्रह्मण उपादानत्वभङ्गः ॥

End :

केचित्तु उपास्त इति श्रवणात् पुंप्रयत्नसाध्यज्ञानविजातीयवृत्त्यन्तररूपोपासनाया एव निषेधः । ननु ज्ञानस्येत्या . . . . ब्रह्मैव भवतीति अत्रापि द्वितीयो ब्रह्मशब्दो जीवपरः । ब्रह्मजातिजीवकमलासनशवर . । ... दिष्विति वचनात् । ब्रह्माणि जीवास्सर्वेऽपिइत्यादिस्मृतेश्च । द्वे ब्रह्मणी वेदितव्ये इत्यादौ जीवेतर . . . .

R. No. 5907

Palm leaf. 16¾ × 1¼ inches. Foll. 181. Lines, 7 in a page. Nandināgarī. Good. Extent, 7,240 Granthas. Printed.

Purchased in 1936–37 from Śrī P. Veṅkataramaṇācāryar, Triplicane, Madras.

ब्रह्मसूत्रभाष्यटीकाव्याख्या by राघवेन्द्रयतिः

भावदीपः

BRAHMASŪTRABHĀṢYAṬĪKĀVYĀKHYĀ BHĀVADĪPAḤ by Rāghavendrayati.

Same work as that described under D. No. 16931.

Breaks off in the third Pāda of second Adhyāya.

R. No. 5908

Palm leaf. 16¼ × 1¼ inches. Foll. 104. Lines, 5 in a page. Nandināgari. Good. Extent, 2,500 Granthas.

Purchased in 1936–37 from Śrī P. Veṅkaṭaramaṇācāryar, Triplicane, Madras.

अभिनवतर्कताण्डवम् by सत्यनाथः

ABHINAVATARKATĀṆḌAVAM by Satyanātha.

Same work as that work described under R. No. 5807. where in this work has been mentioned as " Abhinavatāṇḍava.

Contains Śabdakhaṇḍa incomplete.

Beginning :

नमामि नारायण मादिदेवं लक्ष्मीपतिं सर्वगुणैरुदारम् ।
शब्दैकगम्यं समतीतदोषं श्रीमध्वहृत्पद्मगतं मुदेऽहम् ॥
शिक्षयन्निव दुस्तर्कसर्पमूर्धनि नर्तनम् ।
यश्चकार श्रये कृष्णं कालिकाङ्गेषु नर्तनम् ।
न क्षमा यस्य पुरतः वक्तुं सदसि वादिनः ॥
व्यत्यस्ताखिलविद्यौघाः श्रये सत्यनिधिं गुरुम् ।

. . .

अथ शब्दो निरूप्यते । निर्दोषशब्द आगमः । तस्य दोषाः अबोधकत्वं, विपरीतबोधकत्वं, ज्ञातज्ञापकत्वं अप्रयोजनत्व मनतिप्रयोजनत्व मशक्यसाधनप्रतिपादनलघूपाये सति गुरूपायोपादान मित्यादयः । इयांस्तुविशेषः ।

* * * *

Colophon :

इति तात्पर्यनिरूपणम् ।

Colophon :

इति उदयनोक्तविध्यर्थभङ्गः ।

Colophon :

इति शब्दस्य व्यक्तिशक्तिग्रहे बाधकोद्धारः ।

End :

प्रयोगबाहुल्येन योगमात्राच्च भिन्ना तृतीयेयं वृत्तिरिति । तस्मात् योगरूढिभ्या मित्ययुक्तमिति चेदत्र वक्तव्यम् । योगरूढिभ्यां व्यतिरिक्तेयं वृत्तिः ।

R. No 5909

Palm leaf. 4½ × 1½ inches. Foll. 77. Lines, 7 in a page. Nandināgarī. Injured.

Purchased in 1936–37 from Śrī P. Veṅkaṭaramaṇācāryar, Triplicane, Madras.

(*a*) आह्निकम्

ĀHNIKAM.

Foll. 1*a*—33*b*. Extent, 264 Granthas.

Similar to the work described under D. No. 2824.

Wants end.

Beginning :

ममशरीरस्यान्तर्यामी ऋषिः, अ . . . देवता, प्रकृतिपुरुषः छन्दः, समस्तभूतोच्चाटने विनियोगः ।

अपसर्पन्तु ये भूता ये भूता भुविसंस्थिताः ।
ये भूता विघ्नकर्तार स्ते गच्छन्तु शिवाज्ञया ॥
अपक्रामन्तु भूताद्याः क्रूराश्चैव तु राक्षसाः ।
तेषामप्यविरोधेन ब्रह्मकर्म समारभे ॥

End :

अथ सूर्यमन्त्रः । घृणिस्सूर्य आदित्य इति प्राणायामः । घृणये हृदयाय नमः । सूर्याय शिरसेस्वाहा । आदित्याय शिखायै वैषट् । आदित्याय कवचायहुम् । सूर्याय नेत्रत्रयाय वौषट् । घृणये अस्त्राय फट् । इति दिग्बन्धः ॥

(b) तारतम्यस्तुतिव्याख्या by महाभाष्यरघुनाथयज्वा

TĀRATAMYASTUTIVYĀKHYĀ by Mahābhāṣya Raghunāthayajvan.

Foll. 34a—35b. Extent, 16 Granthas.

In this work, Mahābhāṣya Raghunāthayajvan comments on Tāratamyastuti, which praises Viṣṇu as God par excellence over others.

Complete.

Beginning :

श्रीविष्णुःसकलोत्तमोऽमितगुणोऽनन्तावतारोरमा-

तस्याः कोटिगुणावरौ विधिहरी ताभ्यां च . . . तेगिरौ ।

वीराहीशशिवास्तथैतदवरा वीरादिपश्चावराः

षड्विष्णोर्दयिता विपादिवनिता युग्मावराः षट्कृत ॥

End :

श्रीमत्पूर्णमतिप्रगूढहृदयप्रख्यापनप्रोद्यम-

त्रैलोक्ये . . . जयार्यसत्कृतिसुधग्रन्थादिसद्धर्मना

व्याख्या कार्येण भारतस्य नवनवस्येमंबुधैःसेव्यतां

श्रीविष्णु र्गुरुराजहृत्कमलगः प्रीतोऽस्तु मे विठ्ठलः ॥

इति श्रीमन्महाभाष्य रघुनाथाख्ययज्वना ।

तारतम्यस्तुतिव्याख्या कृता श्रीशस्य तुष्टये ॥

(c) द्वादशस्तोत्रम् by आनन्दतीर्थः

DVĀDAŚASTOTRAM by Ānandatīrtha.

Foll. 36a, 50a. Foll. 50b is left blank. Extent, 60 Granthas. Printed.

Same work as that described under D. No. 10068.

Complete.

(d) विष्णुसहस्रनामस्तोत्रम्

VIṢṆUSAHASRANĀMASTOTRAM.

Foll. 51a—74b. Extent, 200 Granthas. Printed.

Same work as that described under D. No. 9008.

Complete.

(e) श्रीकराक्षरमन्त्रः

ŚRĪKARĀKṢARAMANTRAḤ.

Foll. 75a only. Extent, 4 granthas.
Similar to the work described under D. No. 7436.
Complete.

Beginning :

उत्तिष्ठ श्रीकर स्वाहेति प्राणायामः । भीषयतीति हृदयायनमः । त्रासय त्रासय शिरसे स्वाहा । मर्दय मर्दय शिखायै वौषट् । प्रध्वंसय-प्रध्वंसय कवचाय हुम् । रक्ष रक्ष अस्त्राय फट् । इति दिग्बन्धः । अस्य श्री श्रीकराक्षरमन्त्रस्य

End :

ध्यानम् :—

आदित्यचन्द्रा . . . पंक शांसौ शङ्खप्रसूनाख्यनिधी दधानः ।
द्वाभ्यां कराभ्यां वसु तर्पयन् सः . . . कस्य लक्ष्मीगिरुः संवदः ॥

गरुडारूढ संस्मृत, उत्तिष्ठ श्रीकर स्वाहा इति जपः ।

(f) नृसिम्हमन्त्रः

NṚSIHMAMANTRAḤ.

Foll. 75b—77a. Extent, 16 Granthas.
Same work as that described under D. No. 6519.
Complete.

(g) हंसमन्त्रः

HAṀSAMANTRAḤ.

Foll. 77a and b. Extent, 8 Granthas.
Same work as that described under D. No. 7648.
Complete.

R. No. 5910

Palm leaf. 18 × 1¼ inches. Foll. 27. Lines, 6 in a page. Nandināgarī. Injured. Extent, 800 Granthas.

Purchased in 1936–37 from Śrī P. Veṅkaṭaramaṇācāryar, Triplicane, Madras.

पिनाकिनीमाहात्म्यम्

PINĀKINĪMĀHĀTMYAM.

Same work as that described under D. No. 2466.

Complete.

The Scribe adds:—

दुर्मत्यब्दे मासि माघे कृष्णे कृष्णप्रिये सदा ।
पिनाकिन्याश्च माहात्म्यं लिखितं विदुषां प्रियम् ॥

R. No. 5911

Palm leaf. 14 × 1¼ inches. Foll. 67. Lines, 6 in a page. Nandināgarī. Slightly injured.

Purchased in 1936-37 from Śrī P. Veṅkaṭaramaṇācāryar, Triplicane, Madras.

(a) मायावादखण्डनव्याख्या by जयतीर्थः

MĀYAVĀDAKHAṆḌANAVYĀKHYĀ by Jayatīrtha.

Foll. 1a—13a. Foll. 13b is left blank. Extent, 200 Granthas. Printed.

Complete.

Same work as that described under D. No. 4836.

Complete.

The Scribe adds:—

प्रमोदूतमाघशुक्लद्वितीयायां भानुवासरे संपूर्णम् ।

(b) तत्त्वप्रकाशिकाविवरणम् by जयतीर्थः

TATTVAPRAKĀŚIKĀVIVARAṆAM by Jayatīrtha.

Foll. 14a—35b. Extent, 350 Granthas. Printed.

It is also called upādhikhaṇḍanaṭīkā.

Same work as that described under D. No. 4782.

Complete.

The Scribe adds:—

प्रमोदूतमाघबहुलनवमीभानुवासरे समाप्तम् ।

(c) प्रपञ्चमिथ्यात्वानुमानखण्डनव्याख्या - पञ्चिका by जयतीर्थः

PRAPAÑCAMITHYĀTVĀNUMĀNAKHAṆḌANAVYĀKHYĀ—PAÑCIKĀ by Jayatīrtha.

Foll. 36a—62b. Extent, 835 Granthas. Printed.

Same work as that described under D. No. 4800.

Complete.

The Scribe adds:—

प्रमोदूतफाल्गुनशुद्धदशम्यन्दुवासरे संपूर्णम् ।

(d) मायावादखण्डनम् by आनन्दतीर्थः

MĀYĀVĀDAKHAṆḌANAM by Ānandatīrtha.

Foll. 63a—65a. Extent, 35 Granthas. Printed.
Same work as that described undr D. No. 4835.
Complete.

(e) उपाधिखण्डनम् by आनन्दतीर्थः

UPĀDHIKAṆḌANAM by Ānandatīrtha.

Foll. 65a—66a. Extent, 20 Granthas. Printed.
Same work as that described under D. No. 4781.
Complete.

(f) प्रपञ्चमिथ्यात्वानुमानखण्डनम् by आनन्दतीर्थः

PRAPAÑCANITHYĀTVĀNUMĀNAKHĀṆḌANAM by Ānandatīrtha.

Foll. 66b—67a. Foll. 67b is left blank. Extent, 12 Granthas. Printed.

Same work as that described under D. No. 4799.
Complete.

R. No. 5912

* Palm leaf. 18¾ × 1½ inches. Foll. 227. Lines, 9 in a page. Nandināgarī. Good. Extent, 11,978 Granthas. Printed.

Purchased in 1936-37 from Śrī P. Veṅkaṭaramaṇācāryar, Triplicane, Madras.

तत्त्वप्रकाशिकाव्याख्या

तात्पर्यचन्द्रिका by व्यासतीर्थः

TATTVAPRAKĀŚIKĀVYĀKHYĀ TĀTPARYACANDRIKĀ by Vyāsatīrtha.

Same work as that described under R. No. 4110 (b), where in see for beginning.
Complete.

Colophon :

इति श्रीमद्ब्रह्मण्यतीर्थपूज्यपादानां शिष्येण व्यासयतिना विरचितायां तात्पर्यचन्द्रिकायां द्वितीयाध्यायस्य चतुर्थः पादः ॥

R. No. 5913

Palm leaf. 16¼ × 1-6/16 inches. Foll. 100. Lines, 8 in a page. Telugu. Much injured. Extent, 4,500 Granthas.

Purchased in 1936-37 from P. Veṅkaṭaramaṇācāryar, Triplicane, Madras.

न्यायसुधाव्याख्या by रामचन्द्रभिक्षुः

NYĀYASUDHĀVYĀKHYĀ by Rāmacandrabhikṣu.

This is a commentary on the Nyāyasudhā of Jayatīrtha.

Contains first Adhyāya incomplete.

Beginning :

स्फुटस्य प्रत्यायकत्वमिति द्वितीयपक्षं दूषयति अतिप्रतीतस्यत्विति । अतिप्रतीतस्य स्फुटस्वार्थप्रत्यायकत्वे तस्य सदा सत्वात्सर्वदाऽर्थप्रतीति प्रसङ्ग इत्यर्थः । पूर्वेति पूर्ववर्णानां सम्बन्धस्य च स्मरणेनेत्यर्थः अनुभवस्येति ।

Colophon :

इति श्रीमत्परमहंसपरिव्राजकाचार्यसर्वतन्त्रस्वतन्त्रश्रीमद्व्यासतीर्थमुनिवर्यपौत्रश्रीपतितीर्थपूज्यपादानां शिष्येण रामचन्द्रभिक्षुणा कृतायां श्रीमन्न्यायसुधाव्याख्यायां प्रथमाध्यायस्य प्रथमः पादः ।

Colophon :

इति श्रीमत्परमहंसपरिव्राजकाचार्यसर्वतन्त्रस्वतन्त्रश्रीमद्व्यासतीर्थमुनिवर्यपौत्रश्रीपतितीर्थपूज्यपादानां शिष्येण रामचन्द्रभिक्षुणा कृतायां श्रीमन्न्याय सुधाव्याख्यायां प्रथमाध्यायस्य तृतीयः पादः ।

End :

अन्यथेति । उक्तस्य जयशब्दनिमित्तस्य राज्ञि सत्वेऽपि तस्य तत्र लाक्षणिकत्वं निकारे सजयस्वामिनि राद्येव मुख्यः जयाश्रये भृत्ये तु लाक्षणिक इति वैपरीत्यस्यापातादित्यर्थः । पराजयस्येति । राज्ञि यद्व त्पराजय इति पराजयस्य प्रकृतत्वेऽपि ।

R. No. 5914

Palm leaf. 19 × 2¼ inches. Foll. 530. Lines, 11 on a page. Telugu. Injured.

Purchased in 1936-37 from P. Veṅkaṭaramaṇācāryar, Triplicane, Madras.

(a) प्रमाणलक्षणटीका—न्यायकल्पलता by जयतीर्थः

PRAMĀṆALAKṢAṆAṬĪKĀ—NYĀYAKALPALATĀ by Jayatīrtha.

Foll. 1a—40b. Extent, 1,600 Granthas.

Same work as that described under D. No. 4808.

Wants one leaf in the beginning. Otherwise complete.

(b) तत्त्वसङ्ख्यानविवरणम् by जयतीर्थः

TATTVASAṄKHYĀNAVIVARAṆAM by Jayatīrtha.

Fol. 41a—45a. Extent, 160 Granthas.

Same work as that described under D. No. 4789.

Complete.

(c) तत्त्वविवेकव्याख्या by जयतीर्थः

TATTVAVIVEKAVYĀKHYĀ by Jayatīrtha.

Fol. 45a—48b. Extent, 130 Granthas.

Same work as that described under D. No. 4786.

Complete.

(d) मायावादखण्डनटीका by जयतीर्थः

MĀYĀVĀDAKHAṆḌANAṬĪKĀ by Jayatīrtha.

Foll. 49a—52b. Extent, 120 Granthas.

Same work as that described under D. No. 4836.

Complete.

(e) तत्त्वप्रकाशिकाविवरणम् by जयतीर्थः

TATTVAPRAKĀŚIKĀVIVARAṆAM by Jayatīrtha.

Foll. 53a—59b. Extent, 210 Granthas.

Same work as that described under D. No. 4782, wherein this work has been described under the name "Upādhikhaṇḍanaṭīkā."

Complete.

(f) प्रपञ्चमिथ्यात्वानुमानखण्डनव्याख्या—पञ्चिका— by जयतीर्थः

PRAPAÑCAMITHYĀTVĀNUMĀNAKHAṆḌANAVYĀKHYĀ—PAÑCIKĀ by Jayatīrtha.

Foll. 60a—66a. Extent, 200 Granthas.

Same work as that described under D. No. 4800.

Complete.

(g) तत्त्वोद्योतविवरणम् by जयतीर्थः

TATTVODYOTAVIVARAṆAM by Jayatīrtha.

Foll. 66b—100b. Extent, 1,300 Granthas.

Same work as that described under D. No. 4792.

Complete.

(h) ब्रह्मसूत्रभाष्यव्याख्या—तत्त्वप्रकाशिका by जयतीर्थः
BRAHMASŪTRABHĀṢYAVYĀKHYĀ—TATTVAPRAKĀŚIKĀ by Jayatīrtha.

Foll. 132a—411b. Extent, 11,200 Granthas.
Same work as that described under D. No. 4813.
Complete.

(i) प्रश्नोपनिषद्भाष्यविवरणम् by जयतीर्थः
PRAŚNOPANIṢADBHĀṢYAVIVARAṆAM by Jayatīrtha.

Foll. 513a—524b. Extent, 200 Granthas.
Same work as that described under R. No. 453 (a).
Complete.

(j) ईशावास्योपनिषद्भाष्यटीका by जयतीर्थः
ĪŚĀVĀSYOPANIṢADBHĀṢYAṬĪKĀ by Jayatīrtha.

Foll. 524b, 530b. Extent, 210 Granthas.
Same work as that described under R. No. 493.
Complete.

R. No. 5915

Palm leaf. 19 × 1½ inches. Foll. 63. Lines, 6 on a page. Nandināgari. Slightly injured.

Purchased in 1936-37 from Śrī P. Veṇkaṭaramaṇāchāryar, Triplicane, Madras.

गरुडपुराणम्
GARUḌAPURĀṆAM.

Foll. 1a—63b. Extent, 2,700 Granthas.
Same work as that described under D. No. 2109.
Contains 1 to 16 adhyāyās.

R. No. 5916

Palm leaf. 15¾ × 1½ inches. Foll. 150. Lines, 6 on a page. Nandināgari. Injured.

Purchased in 1936-37 from Śrī P. Veṇkaṭaramaṇāchār, Triplicane, Madras.

(a) तत्त्वप्रकाशिकाटीकाव्याख्या—भावदीपिका by अनन्तः
TATTVAPRAKĀŚIKĀṬĪKĀVYĀKHYĀ—BHĀVADĪPIKĀ by Ananta.

Foll. 1a—5a. Extent, 80 Granthas.

Same work as that described under R. No. 3928 (l) wherein this work has been described under the name "Upādhikhaṇḍanaṭikāvyākhyā."

Complete.

(b) तत्त्वसङ्ख्यानविवरणव्याख्या—तत्त्वदीपिका by अनन्तः
TATTVASAṄKHYĀNAVIVARAṆAVYĀKHYĀ—TATTVADĪPIKĀ by Ananta.

Foll. 5b—9b. Extent, 80 Granthas.
Same work as that described under R. No. 3928 (m).
Complete.

(c) तत्त्वविवेकव्याख्याविवरणम् by अनन्तः
TATTVAVIVEKAVYĀKHYĀVIVARAṆAM by Ananta

Foll. 10a—12b. Extent, 50 Granthas.
Same work as that described under R. No. 3928 (n).
Complete.

(d) तत्त्वोद्योतपञ्चिकाटीका—भावप्रकाशिका by अनन्तः
TATTVODYOTAPAÑCIKĀṬĪKĀ—BHĀVAPRAKĀŚIKĀ by Ananta.

Foll. 13a—39a. Extent, 130 Granthas.
Same work as that described under R. No. 3928 (w).
Complete.

(e) प्रमाणलक्षणपञ्चिकाटीकाविवृतिः by श्रीनिवासः ।
PRAMĀṆALAKṢAṆAPAÑCIKĀṬĪKĀVIVṚTIḤ by Śrīnivāsa.

Foll. 40a—110a. Extent, 1,100 Granthas.
A commentary on the Pramāṇalakṣaṇaṭīkā of Jayatīrtha.
Incomplete.

Beginning :

व्यासं सर्वगुणावासं वासवीनन्दनं प्रभुम् ।
गुर्वाराधितपादाब्जं वन्देऽहं मध्ववल्लभम् ॥
श्रीमदानन्दतीर्थार्यचरणावाश्रयेऽनिशम् ।
रुद्रादिसर्वविबुधैस्संसेव्याविष्टदौ सताम् ॥
श्रीमदानन्दतीर्थार्य शास्त्रदुग्धाब्धिमन्थनात् ।
प्राप्ता ज्ञानसुधा येन तजयेन्द्रमहं भजे ॥
यैरहं शुकवत्सम्यक् शिक्षितोस्मि दयालुभिः ।
तान्वन्दे यादवाचार्यान्वेदेशमुनिसेवितान् ॥
अथैतत्कृपया श्रीनिवासाख्यायुतसूरिणा ।
व्याख्यायते बुद्धिशुद्ध्यै मानलक्षणपञ्चिका ॥

सर्वज्ञकल्पाः टीकाकारा जयतीर्थश्रीमच्चरणाः श्रीमदाचार्यकृतप्रमाण-लक्षणाख्यस्य ग्रन्थस्य टीकां कर्तुकामाः स्वचिकीर्षितस्य ग्रन्थस्य निर्विघ्नेन परिसमाप्त्यर्थं स्वेष्टदेवतादिनतिपूर्वकं मङ्गलं स्वचिकीर्षितं प्रतिजानीते—प्रणम्येति ॥

End :

एवं च हेतोस्स्वरूपस्योचितस्थाने असिद्धः । " प्रमित्यभाव इति—तथाच हेतोस्समुचितदेशोसिद्धेरेव प्रयोजकत्वात् ॥ पक्ष

R. No. 5917

Palm leaf. 13 × 1¼ inches. Foll. 132. Lines, 9 on a page. Nandināgari. Good.

Purchased in 1936-37 from P. Veṅkaṭaramaṇācharyar, Triplicane, Madras.

(*a*) भागवततात्पर्यनिर्णयः by आनन्दतीर्थः ।
BHĀGHAVATATĀTPARYANIRṆAYAḤ by Ānandatīrtha.

Foll. 1*a*—5*a*. Extent, 80 Granthas.
Same work as that described under D. No. 4823.
Incomplete.

(*b*) न्यायसुधाटिप्पणी by यदुपतिः
NYĀYASUDHĀṬIPPAṆĪ by Yadupati.

Foll. 7*a*—80*a*. Extent, 2,000 Granthas.

Same work as that described under R. No. 1285 but with the beginning.
Contains first adhyāya incomplete.

Beginning :

सुसमुखगुणबिम्बस्साधुदत्तावलम्ब
स्सुमतिजलजमोदो दूषितान्यप्रमोदः ।
भुवनविततमोहध्वान्तविध्वंसहेतु
र्दिशतु दिशमभीष्टां व्याससूर्यस्स्वनिष्ठाम् ॥
पूर्णप्रज्ञजयार्यपूर्वकगुरून्नत्वा च विद्याप्रदान्
वेदेशाभिधयोगिनोपि कृपया तेषां सुधाटिप्पणीम् ।
बालानां तनुते मितां यदुपतिर्बोधाय धीशुद्धये
सूक्ष्मानपि प्रविचिन्त्य सद्गुरुमुखात्सम्यक् श्रुतार्थान्मुहुः ॥

न पाण्डित्याभिमानेन नापि मत्सरतः क्वचित् ।
यऽन्नोयं किन्तुधीवाचो विंशुद्ध्यै मम नान्यथा ॥

अथ परमकारुणिको जयतीर्थ श्रीमच्चरणो-
"ग्रन्थोयमपि बह्वर्थो भाष्यं चाल्पर्थविस्तरम् ।
बहुज्ञा एव जानन्ति विशेषेणार्थ मेतयोः ॥"

इत्याचार्योक्तौ लोकानां विश्वासमुपजनयन्ननुव्याख्यानव्याख्यामारममाणोऽभीष्टसमाप्त्यादिप्रयोनकं श्रीपतिस्तुतिप्रमाणरूपं मङ्गलं कृत्वा शिष्य शिक्षायै ग्रन्थादौ तदुपनिबध्नाति—"श्रियः पत्ये" इति

(c) वेङ्कटेशकवचम्

VEṄKEṬEŚAKAVACAM.

Foll. 87a—89a. Extent, 30 Granthas.
Similar to the work described under **R.** 488 (a).
Complete.

Beginning :

अस्य श्रीवेङ्कटेशकवचस्तोत्रमहामन्त्रस्य, ब्रह्मा ऋषिः, अनुष्टुप्छन्दः, परमात्मा श्रीवेङ्कटेशो देवता, ... संस्तुतइति बीजं. श्रीनिवासइति शक्तिः, श्रीवेङ्कटाधिपतिरिति कीलकं, ममसर्वाभीष्टसिद्ध्यर्थे सर्वोपद्रवनाशार्थे जपेविनियोगः ।

End :

सर्वदानेषु यत्पुण्यं सर्वतीर्थेषु यत्फलम् ।
तत्फलं समवाप्नोति कवचं सर्ववर्णकम् ॥
इत्येतत्कवचं पुण्यं त्रिसन्ध्यं यः पठन्नरः ।
प्राप्नोति परमारोग्यं भुक्तिं मुक्तिं च विन्दति ॥

Colophon :

इति श्रीवराहपुराणे श्रीवेङ्कटेशकवचस्तोत्रं संपूर्णम् ॥

(d) ब्रह्मसूत्रभाष्यदीपिका by जगन्नाथयतिः

BRAHMASŪTRABHĀṢYADĪPIKĀ by Jagannāthayati.

Foll. 90a—127b. Extent, 600 Granthas.
Same work as that described under D. No. 4814.

Contains first pāda of second Adhyāya complete and second pāda of second Adhyāya incomplete.

(e) जयतीर्थविजयः by सङ्कर्षणः

JAYATĪRTHAVIJAYAḤ by Saṅkarṣaṇa.

Foll. 128a—132b. Extent, 80 Granthas.

Same work as that described under R. No. 858a.

Contains first sarga incomplete.

R. No. 5918

Palm leaf. 18¼ × 1¾ inches. Foll. 180. Lines, 10 in a page. Nandināgarī. Injured. Extent, 260 Granthas.

Purchased in 1936-37 from Śrī P. Veṅkaṭaramaṇācāryar, Triplicane, Madras.

ऋग्भाष्यटीका by जयतीर्थः

ṚGBHĀṢYAṬĪKĀ by Jayatīrtha.

Same work as that decribed under D. No. 16909.

Wants beginning. Otherwise complete.

R. No. 5919

Palm leaf. 14 × 1½ inches. Foll. 67. Lines, 6 on a page. Nandināgarī. Good.

Purchased in 1936–37, from Śrī P. Veṅkaṭaramaṇācāryar, Triplicane, Madras.

(a) मुक्तावलीव्याख्यानम् - दिनकरीयम् by महादेवः

MUKTĀVALĪVYĀKHYĀNAM—DINAKARĪYAM by Mahādeva.

Foll. 1—50b. Extent, 500 Granthas.

Same work as that described under D. No. 3955.

Contains pratyakṣaparicoheda incomplete.

(b) कुरुस्तोत्रम् by वादिराज

KURUSTOTRAM by Vādirāja.

Foll. 51a—51b. Extent, 10 Granthas.

Stanzas in praise of Viṣṇu by Vādirāja. The author uses the word, 'kuru' repeatedly in this stotra thereby asking others to do what all he wants them to do to Lord Viṣṇu.

Complete.

Beginning :

व्याकुर्वन्निजसच्छास्त्रं स्वीकुर्वंश्चैव सन्मतम् ।
हिंकुर्वन्ममताचारं माकुर्वंस्तुतविस्मृतिम् ॥
नत्वं कुरु गुरून्पूज्यान्माहं कुरु कदाचन ।
अलंकुरुच दुर्गोष्ठीं नालं कुरु रेः कथाम् ॥

End :

बन्दीकुरु हरेर्भक्तिं मन्दीकुरुपुनर्भवम् ।
हर्यैकनिश्चतासिन्धौ वादिराजोहरेः स्तुतौ ॥

* * * *

Colophon :

इति कुरुस्तोत्रं संपूर्णम् ॥

(c) दुर्गास्तवः by वादिराजः

DURGĀSTAVAḤ by Vādirāja.

Foll. 51b—53a. Extent, 35 Granthas.

Similar to the work described under R. 3022 (f).

Complete.

Beginning :

स्त्रीवहदुस्तनरो . . . तमसोग्रतमोनमः ।
नरको नरकोवातं मतिमानतिवर्तते ॥
नरकान्तकपादाब्जपरिचर्यापरान्नरान् ।
विना विनायका स्सर्वा . . . तेरतः ॥

End :

इमं दुर्गास्तवं पुण्यं वादिराजयतीरितम् ।
पठन्द्विजोयस्त्रीरात्रं मृत्युदुर्गाणिहोत्तरेत् ॥

(d) मुक्तौतारतम्यैक्यप्रकाशः

MUKTAUTĀRATAMYAIKYAPRAKĀŚAḤ.

Foll. 54a—57a. Extent, 60 Granthas. A treatise, in the light of the Dvaita School, dealing with the question of equality and unequality of the individual souls in the state of release.

Complete.

Beginning :

ननु तथापि "निरञ्जनः परमं साम्यमुपै ती"ति श्रुत्या भगवता मुक्तानां परस्परं साम्यमङ्गीकृतमस्माभिः, भवन्तस्तु तारतम्यं वदन्ति । अतो मुक्तौ तारतम्यतदभावोक्त्या आवयोर्दोषैक्यमितिचेदत्रब्रूमः

End :

तद्गतमुखोधर्मवत्वरूपमुख्यसाम्यायोगेनामुख्यसाम्यस्य मुख्यतारतम्यादिना . . . भूतत्वेनास्म (?) तैक्ये विवादाभावादिति सर्वमनवद्यम् ।

(e) वेदान्तविषयः

VEDĀNTAVIṢAYAḤ.

Foll. 58a—64a. Extent, 130 Granthas.

A treatise, according to the Dvaita school dealing with the problem of enjoyment after release. The nature of release is discussed here.

Complete.

Beginning :

ननु तथापि मन्मते ब्रह्मानन्दावाप्तिरेव मोक्षः, भवन्मतेतु स्वरूपानन्दानुभवः, एतद्विषये कथमैक्यमितिचेदुच्यते । ब्रह्मानन्दस्यानुभूतिश्रुतयो न मुख्यतः, मुक्तजीवस्यानुभवो मुख्य इतीर्यते ॥

End :

वर्णानित्यत्वं, संसर्गाभावस्याधिकरण स्वरूपत्वं, भगवत्प्रीत्यप्रीती, धर्माधर्मौ इत्यादि प्रमेयम् ॥ इतिनिगदितः प्रीतः पीताम्बरोपि तथाकरोत् ॥

(f) तत्त्वचिन्तामणिदीधितिप्रकाशिका by गदाधरः

TATTVACINTĀMAṆIDIDHITIPRAKĀŚIKĀ by Gadādhara

Foll. 65a—67a. Extent, 40 Granthas.

Same work as that described under D. No. 4049.

Contains Pañcalakṣiṇī incomplete.

R. No. 5920

Palm leaf. 7 × 1¼ inches. Fol. 129. Lines, 9 in a page. Nandināgari. Slightly injured.

Purchased in 1936-37 from Śrī Veṅkaṭaramaṇāchāryar, Triplicane, Madras.

(*a*) ब्रह्मसूत्रभाष्यम् by आनन्दतीर्थः

BRAHMASŪTRABHĀṢYAM, by Ānandatīrtha.

Foll. 1*a*—118*b*. Extent, 1900 Granthas.
Same work as that described under D. No. 4810.
Complete.

(*b*) ब्रह्मसूत्रम् by व्यासः

BRAHMASŪTRAM by Vyāsa.

Foll. 118*a*—129*b*. Extent, 200 Granthas.
Same work as that described under D. No. 4650.
Complete.

R. No. 5921

Palm leaf. 14 × 1¼ inches. Foll. 64. Lines, 8 in a page. Nandināgarī. Much injured. Many leaves are broken. Extent, 400 Granthas.

Purchased in 1936-37 from Śrī P. Veṅkaṭaramaṇāchāryar, Triplicane, Madras.

(*a*) प्रमाणलक्षणटीका by जयतीर्थः

PRAMĀṆALAKṢAṆAṬĪKĀ by Jayatīrtha.

Foll. 1*a*—27*a*.
Same work as that described under D. No. 4808.
Complete.

(*b*) तत्त्वसंख्यानविवरणम् by जयतीर्थः

TATTVASAṄKHYĀNAVIVARAṆAM by Jayatīrtha.

Foll. 27*a*—31*a*. Extent, 120 Granthas.
Same work as that described under D. No. 4789.
Complete.

(*c*) तत्वविवेकविवरणम् by जयतीर्थः

TATTVAVIVEKAVIVARAṆAM by Jayatīrtha.

Foll. 31*a*—35*a*. Extent, 120 Granthas.
Same work as that described under D. No. 4786.
Complete.

(*d*) मायावादखण्डनविवरणम् by जयतीर्थः

MĀYĀVĀDAKHAṆḌANAVIVARAṆAM by Jayatīrtha.

Foll. 35*a*—39*b*. Extent, 130 Granthas.
Same work as that described under D. No. 4836.
Complete.

(e) तत्त्वप्रकाशिकाविवरणम् by जयतीर्थः
TATTVAPRAKĀŚIKĀVIVARAṆAM by Jayatīrtha.

Foll. 40a—46a. Extent, 150 Granthas.

Same work as that described under D. No. 4782, wherein it has been described under the name Upādhikaṇḍanaṭīkā.

Complete.

(f) प्रमाणपद्धतिः by जयतीर्थः
PARAMĀṆAPADDHATIḤ by Jayatīrtha.

Foll. 47a—64a. Extent, 850 Granthas.

Same work as that described under D. No. 4803.

Complete.

R. No. 5922

Palm leaf. 17¼ × 1¼ inches. Foll. 104. Lines, 6 on a page. Nandināgarī. Injured. Extent, 2,808 Granthas.

Purchased in 1936–37 from Śrī P. Veṅkaṭaramaṇācāryar, Triplicane, Madras.

छान्दोग्योपनिषदर्थसंग्रहः by राघवेन्द्रयतिः
CHĀNDOGYOPANIṢADARTHASAṄGRAHAḤ by Rāghavendrayati.

Same work as that described under No.

Contains 1 to 6 complete and 7th incomplete.

R. No. 5923

Palm leaf. 18¾ × 1½ inches. Foll. 75. Lines, 9 on a page. Nandināgarī. Much injured. Extent, 3,037 Granthas.

Purchased in 1936–37 from Śrī P. Veṅkaṭaramaṇācāryar, Triplicane, Madras.

विष्णुतत्त्वनिर्णयव्याख्या by जयतीर्थः ।
VIṢṆUTATTVANIRṆAYAVYĀKHYĀ by Jayatīrtha.

Same work as that described under D. No. 4843.

Contains 1st complete and 2nd incomplete.

R. No. 5924

Palm leaf. 16 × 1½ inches. Foll. 154. Lines, 9 in a page. Nandināgarī. Injured. Extent, 5,544 Granthas.

Purchased in 1936–37 from Śrī P. Veṅkaṭaramaṇācāryar, Triplicane, Madras.

विष्णुतत्त्वनिर्णयव्याख्या by जयतीर्थः
VIṢṆUTATTVANIRṆAYAVYĀKHYĀ by Jayatirtha.

Same work as that described under D. No. 4843

Complete in 3 Paricchedās.

R. No. 5925

Palm leaf. 19 × 1¼ inches. Foll. 79. Lines, 10 on a page. Nandināgarī. Injured. Extent, 3,555 Granthas. Printed.

Purchased in 1936-37 from Śrī P. Veṅkaṭaramaṇācāryar, Triplicane, Madras.

भगवद्गीतातात्पर्यनिर्णयटीका—न्यायदीपिका - by जयतीर्थः
BHAGAVADGĪTĀTĀTPARYANIRṆAYAṬĪKĀ—NYĀYADĪPIKĀ by Jayatirtha.

Same work as that described under No. R. 4126.
Complete.

R. No. 5926

Palm leaf. 11¼ × 1¼ inches. Foll. 177. Lines, 10 in a page. Telugu. Much injured. Extent, 5,575 Granthas. Printed.

Purchased in 1936-37 from Śrī P. Veṅkaṭaramaṇācāryar, Triplicane, Madras.

महाभारततात्पर्यनिर्णयः by आनन्दतीर्थः
MAHĀBHĀRATATĀTPARYANIRṆAYAḤ by Ānandatīrtha.

Same work as that described under D. No. 4824.
Contains 1 to 32 Adhyāyas. Wants the end.

R. No. 5927

Palm leaf. 17 × 1½ inches. Foll. 16. Lines, 8 on a page. Nandināgarī. Injured. Extent, 496 Granthas. Printed.

Purchased in 1936-37 from Śrī P. Veṅkaṭaramaṇācāryar, Triplicane, Madras.

मीमांसान्यायप्रकाशः by आपदेवः
MĪMĀṂSĀNYĀYAPRAKĀŚAḤ by Āpadeva.

Same work as that described under D. No. 4405.
Incomplete.

(b) भाट्टदीपिका by खण्डदेवः

BHĀṬṬADĪPIKĀ by Khaṇḍadeva.

Foll. 17—48. Extent, 868 Granthas. Printed.

Same work as that described under D. No. 4423.

Foll. 37 and 38 and 49—53 left blank.

Contains first two Adhyāyas. Incomplete.

(c) गदाधरीयक्रोडपत्रम्

GADĀDHARĪYAKRḌAPATRAM.

Foll. 54—83. Extent, 696 Granthas.

Similar to the work described under D. No. 4238.

Contains Pañcalakṣaṇi and caturdaśalakṣaṇī, etc.

Beginning :

अव्यभिचरितत्वस्यैव पक्षत्वे पक्षानुगतंदुर्वहं । अतः तत्पदार्थस्य पक्षत्वं स्वीकृतं । अत्रहेतुपद मनिवेश्याव्यभिचारपदार्थविषयताघटित-धर्मावच्छिन्नत्वाभावसाधने वह्न्यभाववदवृत्ति . . . .

End :

वह्निमान् धूमादित्यादौ दोषवारणार्थ मेवाधिकरणपदं । तत्राधि करणपदार्थैकदेशे अधिकरणत्वे साध्यनिष्ठाधेयत्वानिरूपकत्वस्यान्नोक्तदोषः तदस . . तया सत्यपि धूमाद्यधिकरणता मादायोक्तदोषस्य दुर्वारत्वात् साध्य . . . धेयत्वानिरूपिताधिकरणत्वाभावविशिष्टार्थ बोधकत्वादनधि-करणपदस्येति न दोषइति ध्येयम् । इति सार्वभौमपरिष्कारोपरि विचारः

R. No. 5928

Palm leaf. 14¼ × 1½ inches. Foll. 98. Lines, 7 on a page. Nandināgari. Good. Extent, 2,144 Granthas.

Purchased in 1936-37 from Śrī P. Veṅkaṭaramaṇācāryar, Triplicane, Madras.

मध्वविजयव्याख्या—पदार्थप्रकाशिका - by आनन्दतीर्थः

MADHVAVIJAYAVYĀKHYĀ PADĀRTHAPRAKĀŚIKĀ by Ānandatīrtha.

Same work as that described under D. No. 12162.

Contains 2 to 7 Sargās.

R. No. 5929

Palm leaf. 18 × 1½ inches. Foll. 261. Lines, 7 on a page. Nandinägari. Extent,

Purchased in 1936-37 from Śrī P. Veṅkaṭaramaṇācāryar, Triplicane, Madras.

(a) ब्रह्मसूत्रानुव्याख्यानटीका—न्यायसुधा by जयतीर्थः

BRAHMASŪTRĀNUVYĀKHYĀNAṬĪKĀ—NYAYASUDHĀ by Jayatīrtha.

Foll. 1a—190b. Extent, 5985 Granthas. Printed.

Same work as that described under D. No. 4820.

Contains 3 and 4 Adhyāyas.

(b) भगवद्गीतातात्पर्यनिर्णयटीका by जयतीर्थः

BHAGAVADGĪTĀTĀTPRAYANĪRṆAYATĪKĀ by Jayatīrthaḥ.

Foll. 191—261. Extent, 2205 Granthas. Printed.

Same work as that described under No. R. 4126.

Complete.

R. No. 5930

Palm leaf. 18¾ × 1½ inches. Foll. 265. Lines, 7 on a page. Nandināgari. Injured. Extent, 9,400 Granthas.

Purchased in 1936-37 from Śrī P. Veṅkaṭaramaṇācāryar, Triplicane, Madras.

छन्दोग्योपनिषद्भाष्यटीका—पदार्थकौमुदी by वेदेशभिक्षुः ।

CHĀNDOGYOPANIṢADBHĀSYAṬĪKĀ — PADĀRTHAKAUMUDĪ by Vedeśabhikṣu.

Same work as that described under No. R. 864.

Complet in 8 Adhyāyas.

R. No. 5931

Palm leaf. 16 × 1 2/16 inches. Foll. 42. Lines, 5 in a page. Nandināgari. Slightly injured. Extent, 670 Granthas.

Purchased in 1936-37 from Śrī P. Veṅkaṭaramaṇācāryar, Triplicane, Madras.

तर्कसंग्रहवाक्यार्थनिरुक्तिः by पट्टाभिरामः

TARKASAṄGRAHAVĀKYĀRTHANIRUKTIḤ by Paṭṭābhirāma.

Same work as that described under D. No. 4184.

Complete.

R. No. 5932

Palm leaf. 15 × 1¼ inches. Foll. 11. Lines, 6 in a page. Nandināgarī. Injured. Extent, 250 Granthas.

Purchased in 1936-37 from Śrī P. Veṅkaṭaramaṇācāryra, Triplicane, Madras.

प्रणवदर्पणखण्डनम् by विजयीन्द्रतीर्थः

PRAṆAVADARPAṆAKHAṆḌANAM by Vijayīndratīrtha.

This is also called Oṅkāravāda.
Same work as that described under D. No. 4798.
Complete.

R. No. 5933

Palm leaf. 15¾ × 1¼ inches. Foll. 86. Lines, 6 in a page. Nandināgarī. Good.

Purchased in 1936-37 from Śrī P. Veṅkaṭaramaṇācaryar, Triplicane, Madras.

(*a*) ब्रह्मयज्ञप्रयोगः

BRAHMAYAJÑAPRAYOGAḤ.

Foll. 1*a*—2*a*. Foll. 2*b* is left blank. Extent, 25 Granthas.
Same work as that described under D. No. 2846.
Complete.

(*b*) तीर्थप्रबन्धः-गुरुभावप्रकाशिकाव्याख्यासहितः by वादिराज and नारायणाचार्य

TĪRTHAPRABANDHAḤ with commentary Gurubhāvaprakāśikā. The author of the Text Vādirāja and commentator. Nārāyaṇācārya.

Foll. 3*a*—86*a*. Foll. 86*b* is left blank. Extent, 2,000 Granthas. Printed. Complete.

Same work as that described under D. No. 12148 but with the addition of one stanza at the end as given below :—

श्रीवादिराजयोगीन्द्र सेवासन्तुष्टमानसः ।
श्रीवाजिवदनो देवो भावे तिष्टतु सर्वदा ॥

R. No. 5934

Palm leaf. 16¾ × 1¼ inches. Foll. 79. Lines, 9 in a page. Nandināgarī. Good.

Purchased in 1936-37 from P. Veṅkaṭaramaṇāchāryar, Triplicane, Madras.

(*a*) तत्त्वचिन्तामणिव्याख्या - दीधितिः by रघुनाथशिरोमणिः
TATTVACINTĀMAṆIVYĀKHYĀ—DĪDHITIḤ by Raghunāthaśiromaṇi.

Foll. 1*a*—7*a*. Foll. 7*b* is left blank. Extent, 160 Granthas. Printed.
Same work as that described under D. No. 4002.
Contains Vyāptivāda in Anumānakhaṇḍa incomplte.

(*b*) तत्त्वचिन्तामणिदीधितिप्रकाशिका by गदाधरः
TATTVACINTĀMAṆIDĪDHITIPRAKĀŚIKĀ by Gadādhara.

Foll. 8*a*—74*b*. Extent, 2,600 Granthas. Printed.
Same work as that described under D. No. 4045.
Contains Vyāptivāda in Anumānkhaṇḍa.

(*c*) कारकविचारः
KĀRAKAVICĀRAḤ.

Foll. 75*a*—79*a*. Foll. 79*b* is left blank. Extent, 200 Granthas.
Similar to the work described under D. No. 3927 incomplete.

Beginning :

चैत्र त्वयावादीत्यादौ संबोधनेचेतिप्रथमा संबोधनमेवाह । तच्च वक्तुरव्यवहितशब्दजन्यबोधाश्रयत्वेनेच्छा प्रथमार्थताहशे . . . याः . . यतासंबन्धे तु प्रकृत्यर्थदेशवर्णवदाभास, अद्य संबोध्यत्वज्ञानं विचार्यत्वया- भुज्यतामित्यादिवाक्याधीनस्य चैत्रादेः वाक्यार्थबोधस्य भोजनादिप्रवृत्तेश्च निर्वाहात् चैत्रेत्यादिप्रथमान्तपदप्रयोगोऽनर्थकइतिचेत् न ।

End :

प्रामाणिकानां च तथा प्रयोगः । करणं चैत्र इत्यादौ चैत्रादौ धात्वर्थकृते राश्रयतासंबन्धेनान्वयबोधवारणाय तादृशकार्यकारणभावकल्पन मित्यपिन । तादृशबोधे . . . . . वदामः । समभिव्याहार इतरहेतु तथैव उक्तस्थले तादृशबोधवारणसंभवात् ।

R. No. 5935

Palm leaf. 15 × 1 inches. Foll. 68. Lines, 5 in a page. Nandināgari. Injured. Extent, 1,200 Granthas.

Purchased in 1936–37 from Śrī P. Veṅkaṭaramaṇācāryar, Triplicane, Madras.

माघमाहात्म्यम्

MĀGHAMĀHĀTMYAM.

Same work as that described under D. No. 2503.

Contains Adhyāyas 1 to 14 complete. 15 incomplete.

R. No. 5936

Palmleaf. 16¼ × 1⅛ inches. Foll. 81. Lines, 6 in a page. Nandināgari. Injured. Extent, 2,000 Granthas.

Purchased in 1936-37 from P. Veṅkaṭaramaṇāchāryar, Triplicane, Madras.

संग्रहरामायणटिप्पणी

भावरत्नप्रदीपः by विद्याभूषण

SAṄGRAHARĀMĀYAṆAṬIPPAṆĪ. BHĀVARATNAPRADĪPAḤ by Vidyābhūṣaṇa.

Complete.

Same work as that described under D. No. 4846 but with the addition of some stanzas at the beginning as given below :—

Beginning :

देवैर्दिव्यस्तवेन स्तुतगुणनिकरः प्रादुरासीद्रमेशः

पू . . . सुजनसरसिजान्वातसंबोधनाय ।

मन्दारै रिन्दिरायाः करकमलयुगेनानिशं पूजिताङ्घ्रि

रामं लक्ष्मीनिवासं शरणमदगुणं सर्वदाहं प्रपद्ये ॥

आस्थिक्षा नन्तविद्युद्वलय नवघनच्छाय मच्छामितोय-

द्वियोतच्छिन्मयूखप्रसरदमृतसं . . . रा सहस्रम् ।

विद्येशं श्रीशमीशं नलिनसमदृशं सुप्रसन्नाननाब्जं

व्यासं विज्ञानमूर्तिं सकलगुणनिधिं देवदेवं नमामि ॥

* * * *

श्रेष्ठामोपीश पूज्या इतिममगुरवः सज्जनव्रातवन्द्याः

तत्कारुण्यावलोका . . . ततमपि . . . . जसा मत्युदारम् ।

ज्यायान् . . विक्रमार्यप्रवरनरसतो यस्सनारायणाख्यो-

बालानां बोधनाय व्यतनुत सङ्गृह्य रामायणार्थम् ॥

ग्रन्थं सन्निर्णयार्थं विवरण महिमै तस्य किंचित्करिष्ये

दृष्ट्वैत स्साधुभिस्तां न हसत नितरां प्रीतिमेवातनुध्वम् ॥

End : and Colophon :

इति श्रीमत्कविकुलतिलकत्रिविक्रमपण्डिताचार्यसुतश्रीमन्नारायणपण्डितार्यविरचितसंग्रहरामायणस्य श्रीमद्विद्याभूषणवर्यविरचितायां (टिप्पण्यां) उत्तरकाण्डे अष्टमः सर्गः । श्रीमद्विद्याभूषणविरचिता संग्रहरामायणटिप्पणी समाप्ता ।

परामवसंवत्सरे फाल्गुनबहुले त्रयोदश्यां लिखितम् ।

R. No. 5937

Palm leaf. 17 × 1½ inches. Foll. 73. Lines, 6 in a page. Nandināgarī. Slightly injured.

Purchased in 1936–37 from P. Veṅkaṭaramaṇācāryar, Triplicane, Madras.

(*a*) ब्रह्मसूत्रानुव्याख्यानटीका

न्यायसुधा by जयतीर्थः

BRAHMASŪTRĀNUVYĀKHYĀNAṬĪKĀ NYĀYASUDHĀ by Jayatīrtha.

Foll. 1*a*—58*b*. Extent, 1,400 Granthas. Printed.
Same work as that described under D. No. 4820.
Contains the first Adhyāya incomplete.

(*b*) ब्रह्मसूत्रभाष्यम्

BRAHMASŪTRABHĀṢYAM.

Foll. 59*a*—66*b*. Extent, 150 Granthas.

A commentary on the Brahmasūtras in the light of the Advaita School.

Incomplete.

Beginning :

ओं जन्माद्यस्य यतः ओम् । प्रथमसूत्रे विहिता ब्रह्मजिज्ञासा- जन्मादिसूत्रैः क्रियते । ब्रह्मस्वरूपसाधनप . . . . जिज्ञासा हि ब्रह्म- जिज्ञासोच्यते । ब्रह्मण इति कर्मणि षष्ठी परि . . . . प्राधान्यात् ब्रह्मैवसंबध्यते ।

End :

भैवम् । योऽहि कार्यकारणसंबन्धघटादिविविक्तं कर्तृत्वभोक्तृत्वं च दोषसंसर्गिण मात्मानं मत्वा वदयति स जीवोव्यावहारिकएवानेन लक्षणेन । तत्र पदे चैतन्यधातुः सत्यलक्षणोऽनभिमत इत्यभ्युपगमे विरोधाभावात् । नच स . . . .

(c) औपासनप्रयोगः

AUPĀSANAPRAYOGAḤ.

Foll. 67*a*—68*b*. Extent, 40 Granthas.
Similar to the work described under D. No. 2841.
Complete.

Beginning :

यावज्जीवं यावत्सर्वाधानमौपासनं करिष्य इति प्रारभ्य विवाहाग्नौ कुर्यात् ।

End :

होमकर्तृसमस्तस्य नादानं च करोति सः ।
तस्मात्सर्वप्रयत्नेन जिह्वायां होम माचरेत् ॥
हिरण्या कनकी त . . . कृष्णा चैव तु सुप्रभा ।
अतिरिक्ता बहुरूपा हि सप्त जिह्वाः प्रकीर्तिताः ॥

(d) अश्वलायनस्मार्तप्रदीपिका

ĀŚVALĀYANA SMĀRTAPRADĪPIKĀ.

Foll. 69*a*—73*a*. Foll. 73*b* is left blank. Extent, 120 Granthas.
Same work as that described under D. No. 1166.
Contains Sthālīpākakhaṇḍa in the first Adhyāya.

R. No. 5938

Palm leaf. 15¾ × 1½ inches. Foll. 66. Lines, 6 in a page. Nandināgarī. Good.

Purchased in 1936-37 from P. Veṅkaṭaramaṇācāryar, Triplicane, Madras.

(a) ऋक्संहिता

ṚKSAṀHITĀ.

Foll. 1*a*—22*b*. Extent, 500 Granthas. Printed.
Same work as that described under D. No. 1.
Contains Adhyāyas 1 to 3 in the first Aṣṭaka.

(*b*) ऋग्भाष्यम् by आनन्दतीर्थः

ṚGBHĀṢYAM by Ānandatīrtha.

Foll. 23*a*—60*a*. Foll. 60*b* is left blank. Extent, 900 Granthas. Printed.

Same work as that described under D. No. 31.

Complete.

The scribe adds :—

तैलाद्रक्ष जलाद्रक्ष रक्षमां परहस्ततः ।
मूर्खहस्ते न दातव्यमित्थं वदति पुस्तकम् ॥

युवसंवत्सरमार्गशीर्षशुक्लचतुर्थ्यामेतल्लेखनं संपूर्णम् ।

(*c*) संप्रोक्षणविधिः

SAMPROKṢAṆAVIDHIḤ.

Foll. 61*a*—66*b*. Extent, 150 Granthas.

Similar to the work described under D. No. 2907.

Complete.

Beginning :

संप्रोक्षणविधिं वक्ष्ये विष्णुसान्निध्यकारणम् ।
शूद्रस्पृष्टे शुना स्पृष्टे प्रसवे मरणेऽपिच ॥
रजस्वलाप्रवेशे च सेके वर्षजलै रपि ।
पूजायाश्चापि विच्छेदे गर्दभादिप्रवेशने ।

End :

तच्छेषं भुक्त्वा हस्तं प्रक्षाल्याचम्य भगवत्पादोदकं पीत्वा अनेन संप्रोक्षणजपहोमपूजाब्राह्मणसन्तर्पणेन भगवान् अस्मद्गुर्वन्तर्गतश्रीलक्ष्मी-नारायणः प्रीयतामिति समर्पयेत् ॥

The scribe adds :—

युवसंवत्सरमार्गशीर्षशुक्लाष्टम्या मेतल्लेखनं संपूर्णम् ।

R. No. 5939

Palm leaf. $16\frac{3}{4} \times 1\frac{1}{4}$ inches. Foll. 96. Lines, 5 in a page. Nandināgarī. Good.

Purchased in 1936-37 from P. Veṅkaṭaramaṇācāryar, Triplicane, Madras.

(*a*) पदार्थसंग्रहः by पद्मनाभसूरिः
PADĀRTHASAṄGRAHAḤ by Padmanābhasūri.

Foll. 1*a*—26*b*. Extent, 520 Granthas.

Complete.

Same work as that described under D. No. 15717 but with a different colophon as given below.

End :

रघुनाथार्यशिष्येण पद्मनाभेनधीमता ।
कृतः पदार्थसंक्षेपोऽप्यनुगृह्णन्तु सूरयः ॥

Colophon :

इति श्रीपद्मनाभसूरिविरचितः पदार्थसंग्रहः समाप्तः ॥

The scribe adds :

इदं पदार्थसंग्रहपुस्तकं नरसिंह्मेन लिखितम् ।

(*b*) पदार्थससंग्रहव्याख्या
PADĀRTHA SAṄGRAHAVYĀKHYĀ.

Foll. 27*a*—86*b*. Extent, 1460 Granthas.

This is a commentary on Padārthasaṅgraha of Padmanābha which work has been described under above number R. 5939 (*a*).

Incomplete.

Beginning :

कमलाकान्तमानम्य रघुनाथगुरूनपि ।
पदार्थसंग्रहव्याख्यां करिष्यामि यथामति ।

इह खलु जगदुदयादिनिमित्तत्वेन परमात्मतत्त्वज्ञानं मोक्षसाधन मित्यवान्तरानेकभेदभिन्नपदार्थनिरूपणं कुर्वन्ग्रन्थादौ मङ्गल माचरति लक्ष्मपितिमिति ।

End :

ऐतरेयभाष्ये:—

तापिनी पाचिका सैव शोषणी च प्रकाशिनी ।
नैव राज प्रवेदाहिशक्ति नारायणस्य च ॥ इति ।

लक्ष्म्यास्तु प्रलयकालीनाग्निरूपदुर्गास्वरूपत्वात् । नहि प्रसिद्धाग्ने ब्रह्माण्डासर्वदाहकत्वशक्तिर्दृश्यते । मैवं मु . . . नामपि तेजोरू- पत्वं . . .

(c) वायुस्तुतिः
VĀYUSTUTIḤ.

Foll. 87a—89a Extent, 50 Granthas.

This is taken from Skāndapurāṇa. This is similar to the work described under D. No. 9810.

Complete.

Beginning :

श्रीनारदः—

वायोः वरूपं वक्ष्यामि नीलजीमूतसन्निभम् ।
महानादं महाकायं सृष्टिसंहारकारणम् ॥
उद्यदादित्यसङ्काशं नेत्रद्वयसमन्वितम् ।
देवदानवगन्धर्वयक्षराक्षससेवितम् ॥

Colophon :

इति श्रीस्कान्दपुराणे कुमारकाण्डे वायुप्रशंसनं नामषोडशोऽध्यायः ।

End :

तस्मात्त्वं संशयं त्यक्त्वा सेवां कुरु सुखीभव ।
वायु माश्रित्य देवेन्द्र सुरान्पालय शक्तितः ॥

Colophon :

इति श्रीस्कान्दपुराणे कुमारकाण्डे इन्द्रनारदसंवादे वायुप्रशंसनं नामाष्टादशोऽध्यायः ।

(d) मध्वाचार्यप्रशंसा
MADHVĀCĀRYAPRAŚAMSĀ.

Foll. 89a—91a. Extent, 50 Granthas.

This is taken from Brahmāṇḍapurāṇa similar to the work described under R. No. 1447 (c).

Complete.

Beginning :

सूत उवाच

पुण्ये भारतवर्षेऽस्मिन्कर्मभूमा . . . . . . दि ।
अतिपुण्यप्रदे रम्ये क्षेत्रे . . . . . संज्ञिते ।
. . . . . . त्मकं पाणिपीठं धृत्वा समुदितः प्रभुः ।
लिङ्गाकारशिता मूर्ति र्वस्तेऽनन्तासनो हरिः ।

End :

जयत्यनन्तासनोऽयं कृष्णाख्यो जयति प्रभुः ।
तत्पादसक्तो जयति मध्वस्तज्जगतां प्रभुः ॥
इयं कथा गोप्यतमा बहुपुण्यप्रदा द्विजाः ।
मया काश्यपमुखतः श्रुता योगीन्द्रसंसदि ॥

Colophon :

इति श्रीब्रह्माण्डपुराणे मन्त्रभागे . . . . विंशोऽध्यायः ।

(*e*) ग्रन्थमालिकास्तोत्रम्

GRANTHAMĀLIKĀSTOTRAM.

Foll. 91*a* and *b*. Extent, 12 Granthas.
Same as the work described under R. No. 1452 (*d*).
Complete.

(*f*) सालग्राममहिमा

SĀLAGRĀMAMAHIMĀ.

Foll. 92*a*—95*b*. Extent, 85 Granthas.
Foll. 96. Contains a small portion of Pramāṇapaddhati.
Similar to the work described under D. No. 5809.
Incomplete.

Beginning :

ब्रह्मोवाच—

भगवन् श्रीपते ब्रूहि सालग्रामशिलास्थितिम् ।
तत्तीर्थस्य च माहात्म्यं शंस तीर्थस्य च प्रभो ॥
केषां योगे तु तीर्थं स्यात् सालग्रामस्य वै हरेः ।
केऽत्राभिमानिनोदेवाः देवताश्च विशेषतः ॥

End :

पूजकान्तर्गतो विष्णुः पूज्यबिम्बस्थितः स्वयम् ।
स्वं रूपं पूजयत्यर्थात् तथा पूजकसंस्थितम् ॥
स्वस्वरूपं पूजयति पूज्यबिंबस्थितो हरिः ।
पूज्यपूजकरूपेण भोक्तृमेम्याम . . . . ॥

R. No. 5940

Palm leaf. 13 × 1¼ inches. Foll. 10. Lines, 6 in a page. Nandināgarī. Injured. Extent, 250 Granthas.

Purchased in 1936–37 from P. Veṅkaṭaramaṇācāryar, Triplicane, Madras.

तत्त्वसङ्ख्यानविवरणविवृतिः

TATTVASAṄKHYĀNAVIVARAṆAVIVṚTIḤ.

Similar to the work described under R. No. 3928 (*m*).

This is a commentary on Tattvasaṅkhyānavivaraṇa of Jayatīrtha.

Incomplete.

Beginning :

प्रणम्या गण्यकल्याणगुणं श्रीप्राणनायकम् ।
विवृणोमि यथाबोधं तत्त्वसंख्यानपत्रिकाम् ॥

ग्रन्थादौ देवतानतिगुरुनतिरूपम (ङ्गलमनुस्मरन्) रन्, चिकीर्षितं प्रतिजानीते लक्ष्मीपतेरिति ।

End :

विवृण्वन् जगदुपादानतया सर्वस्य जन्मादिकर्तृत्व (मुप) पादयन तत्प्रीति मर्थयते पद्येति । लक्ष्मीसखः, ब्रह्मा तदिच्छयेत्यनेनोपादानत्व व्युदासो नापा . . . . . .

R. No. 5941

Palm leaf. 15½ × 1½ inches. Foll. 83. Lines, 6 in a page. Nandināgarī. Injured. Extent, 2,000 Granthas. Printed.

Purchased in 1936–37 from P. Veṅkaṭaramāṇācāryar, Triplicane, Madras.

व्युत्पत्तिवादः by गदाधरः

VYUTPATTIVĀDAḤ by Gadādhara.

Same work as that described under D. No. 4290.

Contains from Dvitīyāvibhaktivicāra to Saptamīvibhaktivicāra.

R. No 5942

Palm leaf. 14 × 1½ inches. Foll. 178. Lines, 8 in a page. Nandināgarī. Slightly injured. Extent, 3,000 Granthas.

Purchased in 1936–37 from P. Veṅkaṭaramaṇācāryar, Triplicane, Madras.

संग्रहरामायणम् by नारायणपण्डितः

SAṄGRAHARĀMĀYAṆAM by Nārāyaṇapaṇḍita.

Same work as that described under R. No. 448.
Breaks off in 15th Sarga of Yuddhakāṇḍa.

R. No. 5943

Palm leaf. 12¾ × 1½ inches. Foll. 13. Lines, 6 in a page. Nandināgarī. Good. Extent, 250 Granthas.

Purchased in 1936–37 from P. Veṅkaṭaramaṇācāryar, Triplicane, Madras.

अणुमध्वविजयः by नारायणपण्डित

AṆUMADHVAVIJAYAḤ by Nārāyaṇapaṇḍita.

Same work as that described under D. No. 12144.
Complete.

R. No. 5944

Palm leaf. 15¼ × 1½ inches. Foll. 106. Lines, 7 in a page. Nandināgarī. Slightly injured. Extent, 3,200 Granthas.

Purchased in 1936–37 from P. Veṅkaṭaramaṇācāryar, Triplicane, Madras.

न्यायसिद्धान्तमञ्जरीदीपिका—तर्कप्रकाशिका by श्रीकण्ठः

NYĀYASIDDHĀNTAMAÑJARĪDĪPIKĀ—TARKAPRAKĀŚIKĀ by Śrīkaṇṭha.

Same work as that described under D. No. 4223.
Contains Pratyakṣakhaṇḍa to the end of Upamānakhaṇḍa.

R. No. 5945

Palm leaf 19¾ × 1½ inches. Foll. 88. Lines, 8 in a page. Nandinagari. injured. Extent, 4,400 Granthas. Printed.

Purchased in 1936–37 from P. Veṅkaṭaramaṇācāryar, Triplicane, Madras.

न्यायामृतम् by व्यासयतिः

NYĀYĀMṚTAM by Vyāsayati.

Same work as that described under D. No. 4796.
Contains the first Pariccheda complete.

R. No. 5946

Palm leaf. 19 × 1¼ inches. Foll. 82. Lines, 8 in a page. Nandināgarī. Good. Extent, 4,000 Granthas. Printed.

Purchased in 1936-37 from P. Veṅkaṭaramaṇācaryar, Triplicane, Madras.

तर्कताण्डवम् by व्यासतीर्थः

TARKATĀṆḌAVAM by Vyāsatīrtha.

Same work as that described under R. No. 5903 but wants the first Pariccheda in that manuscript.

Breaks off in Upasargavācakatvasamarthana of the second Pariccheda.

Beginning :

अनन्तकल्याणगुणैकराशि मशेषदोषोज्झित मप्रमेयम् ।
मुमुक्षुभिः सेव्य मनन्तसौख्यप्रदं रमेशं प्रणमामि नित्यम् ॥
श्रीशपादाम्बुजासक्तः करुणापूरशीतलः ।
मध्वाख्यो मरुदंशो मे सन्तापान्हन्तु सन्ततम् ॥
आनन्दतीर्थोपदिष्टो निधि र्नारायणाह्वयः ।
प्रदर्शितो येन सम्यक् जयतीर्थं तमाश्रये ॥
श्रीमदानन्दतीर्थार्यस्वामिनः कमलापतेः ।
प्रीतये क्रियते व्यासयतिना तर्कताण्डवम् ॥

Colophon :

इति श्रीब्रह्मण्यतीर्थपूज्यपादानां शिष्येण व्यासयतिना विरचिते तर्कताण्डवे प्रथमः परिच्छेदः ।

End :

एतदेवाभिप्रेत्योक्तं भगवत्पादैः
समितीत्युपसर्गेण परमुख्यार्थतोच्यते । इति ।
उपसंक्रमणंचैव द्वितीयोद्देशितं प्रति ॥
अतिक्रमं वदन्तं तमुपशब्दो निवारयेत् । इतिच ।

Colophon :

उपसर्गाणां वाचकत्वसमर्थनम् ।

R. No. 5947

Palm leaf. 10 × 2 inches. Foll. 113. Lines, 12 in a page. Nandināgari. Injured. Extent, 5,650 Granthas. Printed.

Purchased in 1936-37 from P. Veṅkaṭaramaṇācāryar, Triplicane, Madras.

छान्दोग्योपनिषद्भाष्यटीका — पदार्थकौमुदी by वेदेशभिक्षुः

CHĀNDOGYOPANIṢADBHĀṢYAṬĪKĀ, PADĀRTHAKAUMUDĪ by Vedeśibhikṣu.

Same work as that described under R. No. 864.

Incomplete.

R. No. 5948

Palm leaf. 18½ × 1⅞ inches. Foll. 38. Lines, 9 in a page. Nandināgari. Injured. Extent, 2,000 Granthas.

Purchased in 1936-37 from P. Veṅkaṭaramaṇācāryar, Triplicane, Madras.

तत्त्वमञ्जरी by रघुनाथयतिः

TATTVAMAÑJARĪ by Raghunāthayati.

A treatise on the tenets of the Dvaita school. The author Raghunāthayati mentions 21 predecessors in the field such as, Bhārativijaya, Saccidānanda, Brahmaneṣa, Śatānanda, Vijaya, Bhedarudra, Vāmana, Rāmānuja, Bahṛtṛprapañca, Draviḍa, Brahmadatta, Bhāskara, Jayabhaṭṭa, Viṣṇukrānta, Vādīndra, Mādhava, Śaṅkara and others.

Complete.

Beginning :

यदुपव्यासरामाख्यं ब्रह्म नत्वा गुरूनपि ।
मध्वशास्त्रं समालोच्य करिष्ये तत्त्वमञ्जरीम् ॥

आदौ परम . . . . सर्वोत्तमः गुणभूतसूक्ष्मैः महदहङ्कारबुद्धिमनइन्द्रियमात्राभूतसूक्ष्मैः, नित्यैः कालादृष्टसंस्कारैः, अनित्यैश्च सह, रमालिङ्गितः— शयानआस्ते- तस्यैव परममहत्वं च स एव पदार्थस्य स्वरूपावस्थि तस्य यत् कैवल्यं . . . . . ।

End :

अतएव . . . क्षतानन्त्यायेवा न्येषां भगवत्साम्यमिति चोद्यंनिरस्तम् । निरवधिकानन्त्यस्य विष्णो रेव सुस्थितत्वात् । इति पूर्वोक्तरीत्या सुगममिति सर्वामिति . . . . . ।

रघुनाथयति श्रीशप्रीत्यै श्रीमध्व संवि . . . . ।
ज्ञानकारमणाभ्यां च प्राप्य तत्त्वमञ्जरीम् ॥
भारतीविजयश्चैव सच्चिदानन्द एवच ।
ब्रह्मघोषः शतानन्दो द्वितीयस्येव पञ्चमः ॥
...
विजयो भेदरुद्रश्च वामनस्तु तथाष्टमः ।
रामानुजस्तथा भर्तृप्रपञ्चो द्रविडस्तथा ।
ब्रह्मदत्तो भास्करश्च . . . . वृत्तिकारकः ।
तथापि ज्ञ भट्टश्च विष्णुक्रान्त स्तथैवच ।
वादीन्द्रश्च ततः पश्चात् ततो माधवशासकः ।
ततः पश्चा च्छङ्करश्चे त्येकविंशतिवादिभिः ।
प्रणीतानि निराचक्रे भाष्याणि महामहः ।
...
भाट्टं प्राभाकरं चैव वैशेषिकविनिर्मितम् ॥
वैयासिकं च बौद्धं च चार्वाक मिति षण्मतम् ॥

R. No. 5949

Paper. 10 × 4½ inches. Foll. 11. Lines, 14 on a page. Devanāgarī. Injured. Extent, 360 Granthas.

Purchased in 1936-37 from P. Veṅkaṭaramaṇācāryar, Triplicane, Madras.

गदाधरीयव्याख्या—कृष्णभट्टीया

GADĀDHARĪYAVYĀKHYĀ—KṚṢṆABHAṬṬĪYĀ.

Similar to the work described under D. No. 4073.

Contains pañcalakṣaṇī incomplete.

Beginning :

समारब्धेत्यादिरारभतइत्यन्तो ग्रन्थः किमर्थमित्याशङ्कायां मनुमान प्रामाण्यस्य पूर्वं निरूपितत्वादिदानीं व्याप्तिनिरूपणस्य क्रियमाणत्वादुभयो- र्निरूपणयोस्सङ्गत्यप्रदर्शनेन न्यूनता स्यादिति तयोरुपोद्घातत्वरूपसङ्गतिं प्रदर्शयति । समारब्धेति ।

End :

अथेति । द्रव्यत्वस्याभावरूपतया यत्किञ्चित्संबन्धेन साध्यविशिष्ट साध्यवद्भिन्नावृत्तिद्रव्यत्ववत्वमादायासंभववारणायानुयोगितासंबन्धेन साध्यवैशिष्ट्यनिवेशस्यावश्यकतया तेनैवच द्रव्यत्वादेर्वारणसंभवात् एतछाभावेत्येवा भावपद मिति भावः । नच ॥

R. No. 5950

Paper. 10¾ × 4½ inches. Foll. 4. Lines, 8 on a page. Devanāgarī. Injured.

Purchased in 1936-37 from P. Veṅkaṭaramaṇācāryar, Triplicane, Madras.

गङ्गालहरी by सत्यधर्मयतिः

GAṄGĀLAHARĪ by Satyadharmayati.

Extent, 60 Granthas.

Similar to the work described under R. No. 3337.

Complete.

Beginning :

जले पीते पीते मनसि च शुचित्वं जनकजा
भिरामे श्रीरामे मतिरिति भवेऽस्मिन्नपि भवेत् ।
समूर्धन्ये मूर्धन्यनिमिषपुषो विभ्रतिचयत्
ससोमेसोमेसत्यविकुलललामे यदभवत् ॥

End :

न वानु प्रासो वस्तुपदपदवी नापि च रसो
नवालंकारोऽस्यां फणिनिरपिवा फणितसमा ।
तथापीयं यच्छ्रीदरिचरणजास्तोत्रलहरी
छलद्धर्याहृद्या यतिविरचितेत्यस्तु रुचिता ॥

Colophon :

इति श्रीमत्सत्यवरगुरुचरणाराधक श्रीमत्सत्यधर्मयतिविरचिता गङ्गालहरी संपूर्णा ॥

R. No. 5951

Paper. 11¾ × 4 inches. Foll. 14. Lines, 12 on a page. Devanāgarī. Injured.

Extent, 500 Granthas.

Purchased in 1936-37 from P. Veṅkaṭaramaṇācāryar, Triplicane, Madras.

विरहिमोदः—सव्याख्यः by सत्यधर्मशर्मा

VIRAHIMODAḤ with commentary by Satyadharmaśarman.

A love-poem describing the love-born state of a girl.
Complete.

Beginning :

मू—

सजवयोगवयोगवियोगतो मरणमेवबरं गरयोगतः ।
इतिमतिं तनुते युवती व्रजे परिभवे भवति स्मरतीव्रजे ॥

व्या—

यस्सन्मनसिदूरे मद्दूरे सन्नन्तरेवयः ।
श्रीरस्तुताद्धरे मे श्रीरस्तुमस्तुहरात्ततः ॥
श्रीसत्यसन्ध गुरूराड् पादपाथोजसंगतः ।
पायादपायतोपायाच्छ्रीसत्यवरगन्धभृत् ॥

*　　*　　*　　*

सेति युवती । स्त्रीकाचित्, यु मिश्रण इत्यस्माच्छतरि अनित्या-दिनोवङि ल्गिति ङीपि युवती शब्दो भवति ॥

व्रजे गोकुले । स्मरतीव्रजे, स्मराचीव्रं यथा भवति तथा जायत इति तथा तस्मिन्, परिभवे - पराजये, भवति, सति - सजवयोगवयोग-वियोगतः, जवस्यवेगस्य योगः संबन्धः तेनसहितं सत्सजवयोगं सचवयश्च पक्षी च गरुड इति यावत् ।

End :

मू—

विरहिमोद सुधाविहिता शुभासुनवरत्न भुवाविहिता शुभा ।
सचकृपामृतदोहरिकन्धर स्तदनयास्तुच मे हरिकन्धरः ॥

व्या—

समापितेदं काव्यस्तन्नामकथनपूर्वकमन्तेपि स्वोपास्यं हयास्यं नम-स्यति । विरहीति । विरहिणीनां वियोगिनिनामामोदे मोद-विषये सुधेवसुधा, अमृतसमा, विहिता, विरचिता शुभा मङ्गल-करी । स्ववंशनाम शंसति—सुनवरत्न भुवेति ।

*　　*　　*　　*

हरिकन्धरकन्धरः, हयाननमेघः, अमृतदोऽस्त्वित्यत्रोषमतिमङ्गलम् ॥

Colophon :

इति विरहिमोदव्याख्यापि सकृता समाप्ता ॥

R. No. 5952

Paper. 9 × 5 inches. Foll. 2. Lines, 9 on a page. Devanāgarī. Injured. Extent, 30 Granthas.

Purchased in 1936-37 from P. Veṅkaṭaramaṇācāryār, Triplicane, Madras.

विष्णुपूजाविधिः

VIṢṆUPŪJĀVIDHIḤ.

Similar to the work described under D. No. 8697.

Incomplete.

Beginning :

सदा तवध्येयतयाहदब्जोस्थितमच्युतम् ।
चिद्रूपमद्रावयव चित्रभूषणभूषितम् ॥
सश्रीकं सपरीवारं सर्वज्ञं सर्वसाक्षिणम् ।
आवाह्यप्रतिमामध्ये ध्यायस्व नृतुरङ्गमम् ॥
करस्थमुद्रा शङ्खाक्षपुस्तकं रम्यहस्तकम् ।
चन्द्राभं चन्द्रबिम्बस्थं चन्दनोक्षितवक्षसम् ॥

End :

सद्योविजयदं सिद्धसाध्याराध्यपदं स्मर ।
तत्त्वानां मातृकाणां च वर्णानां चैव देवताः ॥
शास्त्रोक्तवर्त्मना विष्णोरङ्गेष्वर्पय सादरम् ।
पञ्चाङ्गं वा षडङ्गं वा न्यासं तत्र हरेः पुनः ॥

R. No. 5953

Paper. 9¾ × 4 inches. Foll. 61. Lines, 9 on a page. Devanāgarī. Injured. Extent, 900 Granthas.

Purchased in 1936-37 from P. Veṅkaṭaramaṇācāryār, Triplicane, Madras.

प्रमेयसंग्रहः

PRAMEYASAṄGRAHAḤ.

This deals with the description of various islands like Śālmalidvīpa.

Incomplete.

Beginning :

अशेषगुणपूर्णोऽशेषदोषरहितः श्रीब्रह्मादिसकलजीवोत्तमस्तत्प्रेरक . . . . . गजतुरगादिस्थूलसूक्ष्मशरीरस्थतत्तदाकारतत्तत्परिमाण . . . . स्वसंसृष्टं समस्त मचेतनं जगत्स्वयमेव प्रलयकाले संहृत्य चेतनं स्वोदरे निक्षिप नाभेरधोवामभागे प्राप्ततमस्कान् दक्षिणभागे तमोयोग्यान् समप्रदेशे निक्षिप्य प्रकृत्यात्मके प्रलयोदके श्रीरूपवटपत्रे शिशुरूपस्सन् ब्रह्ममानेन शतवर्षपर्यन्तं योगनिद्रामकरोत् ॥

End :

एतादृशशाल्मलिद्वीपस्य तृतीयस्सुरानामकश्चतुर्लक्षविस्तृतस्समुद्र आवारकः । तस्यावारकश्चतुर्थः कुशनामको द्वीपः, सचाष्टलक्षयोजन परिमितः । . . . . . तस्य राजा हिरण्मयः । तस्य सप्तपुत्राः । तेषां क्रमात्सप्तखण्डान् ददौ । तत्र प्रथमखण्डस्य च नामको मर्यादा पर्वतस्सुनाद इति नाम । तन्नामको राजा । सकस्या नदी । द्वितीय-खण्डस्यकृतश्रृङ्गनामको मर्यादापर्वतः । दृढकीर्तिर्नाम । तन्नामको राजा । मधुकुल्यनामिका नदी ॥

R. No. 5954

Paper. $7\frac{1}{4} \times 4$ inches. Foll. 4. Lines, 9 on a page. Devanāgarī. Injured.

Purchased in 1936-37 from P. Veṅkaṭaramāṇācāryar, Triplicane, Madras.

(a) वादिराजकवचम्

VĀDIRĀJAKAVACAM.

Foll. 1a—3a. Extent, 25 Granthas.

Similar to the work described under R. No. 1439 (d).

Complete.

Beginning :

आजह्वालाटे लसदूर्ध्वपुण्ड्रं स्वङ्गारेखाङ्कितमध्यदेशम् ।
आकण्ठमालां विसलम्बमालां मालां तुलस्यक्षमयीं दधानम् ॥
श्रीमुद्राचिह्नितसर्वगात्रं करोल्लसच्छ्रीजपमालिकं परम् ।
हत्पुण्डरीकस्थगुहांबरस्थं वाजीमवक्त्रं सततं स्मरामि ॥

* * * *

वादिराजशिरः पातु भक्तप्राणहृती भवः ।
वादिराजः पातु कालं जगद्वन्द्यपदाम्बुजः ॥

End :

हयग्रीवपदाम्भोजलोलभृङ्गं सतां गुरुम् ।
नमामि श्रीवादिराजं ज्ञानवैराग्यसंपदं ॥
नमः श्रीवादिराजाय गुरवे दीनबन्धवे ।
यो मां वराकिं कृपया मृत्युग्रस्तममूमुचत् ॥

Colophon :

इति श्रीवादिराजकवचं संपूर्णम् ॥
कामधेनुर्यथापूर्वं सर्वाभीष्टफलप्रदा ।
तथाकरो वादिराजश्रीपादोऽभीष्टदस्सदा ॥

(b) यादवाष्टकम्

YĀDAVĀṢṬAKAM.

Foll. 4a—4b. Extent, 10 Granthas.
Similar to the work described under D. No. 10227.
Complete.

Beginning :

वेदेश योगीशपदाब्जसेवा संप्राप्तसंपत्त्यतिशोभमानम् ।
प्रोत्खण्डिताशेषकुवादिमानं श्रीयादवार्यं सुखदं नमामि ॥
श्रीव्यासपादाम्बुजभृङ्गराजं श्रीमत्सुधाम्भोरुह हंसराजम् ।
दुर्वादिनागेन्द्रमृगाधिराजं श्रीयादवार्यं सुखदं नमामि ॥

End :

स्वपक्षसंरक्षणदक्षमन्यपक्षप्रतिक्षेपणदक्षदीक्षम् ।
स्वगोत्रविन्यस्तकृपाकटाक्षं श्रीयादवार्यं सुखदं नमामि ॥
श्रीयादवाष्टकमिदं तत्पदासक्तमानसः ।
श्रीव्यासपादसंसक्तिः पूरयेत्स्वमनोरथः ॥

Colophon :

श्रीयादवाष्टकं समाप्तम् ॥

R. No. 5955

Paper. 9½ × 4½ inches. Foll. 3. Lines, 9 on a page. Devanāgari. Injured. Extent, 40 Granthas.

Purchased in 1936-37 from P. Veṅkaṭaramaṇācāryar, Triplicane, Madras.

केनोपनिषत्.

KENOPANIṢAD.

Same work as that described under D. No. 376.
Complete.

R. No. 5956

Paper. 9½ × 4 inches. Foll. 9. Lines, 10 on a page. Devanagari. Injured. Extent, 120 Granthas.

Purchased in 1936-37 from P. Veṅkaṭaramaṇācāryar, Triplicane, Madras.

तर्पणदर्पणम्.

TARPAṆADARPAṆAM.

Same work as that described under R. No. 96 (*b*) with different end.
Incomplete.

End :

विवाहप्रथमारम्भे सायमाहुतयस्तथा ।
अन्यत्र प्रातराहुत्य इत्याश्वलायनसम्मतम् ॥
विवाहात्परंमकाब्दं मातापित्रोर्मृतेः परम् ।
दैवं पित्र्यं नभुञ्जीयाच्छपन्ति पितृदेवताः ॥

R. No. 5957

Paper. 13½ × 5½ inches. Foll. 33. Lines, 13 on a page. Nandināgari. Injured. Extent, 850 Granthas.

Purchased in 1936-37 from P. Veṅkaṭaramaṇaāchāryar, Triplicane, Madras.

सन्ध्याभाष्यम्.

SANDHYĀBHĀṢYAM.

Similar to the work described under D. No. 2876.
Complete.

Beginning :

लक्ष्मीलक्ष्मीशपादाभ्यामियमस्तु नमस्कृतिः ।
यया निखिलभव्यानि भवेयुर्भजतां हरिम् ॥
श्रुतिस्मृत्युदितं कृत्यं यदाराधनसाधनम् ।
तद्विधायकमन्त्राणां वृत्तिं वक्ष्ये यथाक्रमम् ॥
यावन्तोऽस्यां विकर्मस्थाः पृथिव्यां बालिशाद्विजाः ।
तेषां पावित्र्यसिद्ध्यर्थं सन्ध्या सृष्टा स्वयम्भुवा ॥
उपास्तिस्सन्ध्यौ सूर्यस्य निशाया दिवसस्य च ।
तामेवसन्ध्यां तस्मात्तु प्रवदन्तिमहर्षयइति ॥
अनेनसूर्यान्तर्गतभगवद्ध्यानमेव सन्ध्येत्युक्तं भवति ॥

End :

दामोदरनामार्थः

ददातीतिदाः, सत्पात्रदानशीलाः सज्जनाः तेषामामोदं मोक्षाख्यसुखं दाति ददातीति वा । दमः प्रलयकालः, तत्सम्बन्धि, दामं, दामंचतत् उदं च दामोदं, दामोदेरमत इति वा दामोदरः । पुरुषोत्तमनामार्थः, पुराणिषट्, श्वेतद्वीपानन्तासनवैकुण्ठ सर्वहृदयसत्यलोका व्याकृताकाशाः षट् यस्यासौ, परुषश्चासावुत्तमश्चेतिवा ॥

The Scribe adds :

पार्थिवसंवत्सर श्रावणकृष्णतृतीयायां लेखनं संपूर्णम्

R. No. 5958

Paper. 7¾ × 4 inches. Foll. 3. Lines, 8 in a page. Devanāgarī. Injured. Extent 25 Granthas.

Purchased in 1936–37 from P. Veṅkaṭaramaṇāchāryar, Triplicane, Madras.

कृष्णाष्टकम् by वादिराजः

KṚṢṆĀṢṬAKAM by Vādirāja.

Similar to the work described under R. No. 324 (*k*).

Complete.

Beginning :

मध्वमानसपद्ममानुसमं स्मरप्रतिसंस्मर
स्निग्धनिर्मलशीतकान्तिलसन्मुखं करुणोन्मुखम् ।
हृद्यकम्बुसमानकन्धरमक्षयं दुरितक्षयं
स्निग्धसंस्तुतरौप्यपीठकृतालयंहि रमालयम् ॥

End :

रौप्यपीटकृतालयस्य हरेः प्रियं दुरितापियं
तत्पदार्चकवादिराजयतीरितं गुणपूरितम् ।
गोप्यमष्टकमेतदुच्च मुदे ममास्त्विहनिर्मल
. . . . शुद्धफलाय तत्रसुकोमलं हृतधीमलम् ॥

Colophon :

इति श्रीवादिराजकृतकृष्णाष्टकं संपूर्णम्.

R. No. 5959

Paper. 9 × 4½ inches. Foll. 5. Lines, 10 on a page. Devanāgarī. Injured. Extent, 40 Granthas.

Purchased in 1936-37 from P. Veṅkaṭaramaṇācāryar, Triplicane, Madras.

मुण्डकोपनिषत्

MUṆḌAKOPANIṢAD.

Same work as that described under D. No. 713.
Complete.

R. No. 5960

Paper. 3½ × 3½ inches. Foll. 55. Lines, 9 on a page. Devanāgarī. Injured. Extent, 400 Granthas.

Purchased in 1936-37 from P. Veṅkaṭaramaṇācāryar, Triplicane, Madras.

मध्वविजयः by नारायणपण्डिताचार्यः

MADHVAVIJAYAḤ by Nārāyaṇapaṇḍitācārya.

Same work as that described under R. No. 479.

Contains 15 Sargas complete and 16th Sarga incomplete.

R. No. 5961

Paper. 8 × 4 inches. Foll. 46. Lines, 11 on a page. Devanāgarī. Injured. Extent, 800 Granthas.

Purchased in 1936-37, from P. Veṅkaṭaramaṇācāryar, Triplicane Madras.

तत्त्वसारसंग्रहः by श्रीनिवासः

TATTVASĀRASAṄGRAHAḤ by Śrinivāsa.

A work giving in brief the fundamental principles of the Dvaita school of Vedānta.

Complete.

Beginning :

लक्ष्मीपतिं हयग्रीवं नरसिंहं गुणार्णवम् ।
. . . . व्यास . . . णादिकांनुमः ॥
॰ानन्दतीर्थगुरुराजमीडे श्रीमज्जयार्यंयतिराजम् ।
तद्वंशजातं परहंसराजं श्रीसत्यनाथेन्द्रमहं नमामि ॥
यस्सत्यनाथेन्द्रपदाम्बुजस्य संसेवयावाप्तसमस्तभाग्यः ।
तत्संस्मृतिध्यानपरायणं तं नतोऽस्मि सत्याभिनवीनतीर्थम् ॥
प्रायेणाल्पायुषो मर्त्याः कलावस्मिन्युगेजनाः ।
. . . . मन्दमतयो मन्दभाग्याह्युपद्रिताः ॥
भूरीणि भूरिकर्माणि श्रोतव्यानि विभागश ।
सन्ति तस्मात्संग्रहेण क्रियते ध्यानसंग्रहः ॥

End :

भगवद्ज्ञान भोगाभ्यां निवृत्तसमस्तानिष्टकर्मणः . . . . स्वोचितैर्नार्चिरादिनावा यथा वैकुण्ठलोकवासिनं भगवन्तं, हिरण्यगर्भेणसह भासाभिन्नलिङ्गशरीराः विध्वस्तप्रकृतयोऽत्यन्तनिवृत्तानिष्टाः सम्यगाविर्भूतानन्दादिगुणाः भगवत्समीप एवमुपासिना न कदाचित्पुनरावर्ततइति मोक्षस्वरूपम् ॥

श्रीनिवासाख्यविदुषा रचितस्तत्त्वसंग्रहः ।
मध्वादिसद्गुरूणां च प्रीत्यै भवतु सर्वदा ॥

Colophon :

इति श्रीतत्त्वसारसंग्रहस्समाप्तः ॥

R. No. 5962

Paper. 9 × 4½ inches. Foll. 109. Lines, 11 on a page. Devanāgarī. Slightly injured. Extent, 2,000 Granthas.

Purchased in 1936-37 from P. Veṅkaṭaramaṇācāryar, Triplicane, Madras.

बृन्दावनाख्यानम्

BṚNDĀVANĀKHYĀNAM.

Similar to the work described under D. No. 2480.
Complete.

Beginning :

हयग्रीवं चिदानन्दविग्रहं सदनुग्रहम् ।
दशग्रीवच्छिदं शापान्मणिग्रीवविमोचनम् ॥
सुग्रीवाभयदं सम्यगुग्रसेनविभूतिदम् ।
उग्रविग्रहहन्तारं भक्तामयकरग्रहम् ॥
स्वनामग्रहणादेव निरस्तग्रहविग्रहम् ।
बृन्दावनगतं वन्दे ब्रह्मरुद्रेन्द्रवन्दितम् ॥

* * * *

वनं तु पद्मकं नाम सोमनन्दीवनं तथा ।
ब्रह्मारण्यमिति ख्यातं यद्वनं वर्तते भुवि ॥
आनन्दकाननं चेति यद्वनं वर्तते सदा ।
एतान्यन्यानि पुण्यानि वर्तन्ते भुवि कानिचित् ॥
तानि सर्वाणि वर्तन्ते मम बृन्दावने द्विज ।
तस्माद्बृन्दावनमिदं सर्वाभीष्टप्रदं सताम् ॥

End :

उपलक्षणमेतच्चाप्युपलक्षितमेव च ।
अनेनचोपलक्ष्यस्त्वद्युपलस्थलगां कृतिम् ॥
यथा दधि च काकेभ्यो रक्ष्यतामिति वाक्यतः ।
दध्युपघातुका ग्राह्या ह्याखुमुगादयस्तथा ॥
तस्मान्मत्तपसावापि स्वस्य विश्वासतोपि वा ।
भविष्यति सुषेणाढ्य मत्कार्यं शोषितं त्वयम् ॥

इदं वृन्दावनाख्यानं ये पठन्ति मनीषिणः ।
मुकुन्दवनमेवास्तु तेषां कन्दाशनाज्ञया ॥
एतत्सर्वस्वाप्नपद्येन गर्वं हित्वासर्वेविप्रवर्यास्त्वनेन ॥ !
श्रुत्वाचोन्नीं शर्वगुर्वादिदेवान् दृष्ट्वोर्वेर्वी यान्तु मां मानवेन्द्राः ॥

Colophon :

इति स्वाप्नवृन्दावनाख्याने चरमप्राणावधौ पञ्चमोऽध्यायः ॥ श्रीवायुहनूमद्भीममध्वान्तर्गतश्रीमाधवरामकृष्णवेदव्यासात्मकश्रीहयग्रीवात्मक श्रीरुक्मिणीसत्यासमेतश्रीगोपालकृष्णः प्रीयताम् ॥

R. No 5963

Paper. 8½ × 4¼ inches. Foll. 5. Lines, 8 on a page. Devanāgari. Injured. Extent, 70 Granthas.

Purchased in 1936-37 from P. Veṅkaṭaramaṇācāryar, Triplicane, Madras.

दृश्यत्वविचारः

DṚŚYATVAVICĀRAḤ.

This work contains a series of arguments advanced by the Advaitins to prove that the world we see is only an illusion and these arguments are answered in the light of the Viśiṣṭādvaita school of Vedānta.

Complete.

Beginning :

श्रीश्रीनिवासपरकालयतीश्वराणां
विद्वद्वरिष्ठ(क)कुलिते खलु सन्निधाने ।
योऽभूत्प्रसङ्गवशतो विषयस्सएष
स्संलिख्यते क्रमवशेन कुतूहलेन ॥

तत्रेयं वादिनः प्रथमकक्षा । "विश्वं मिथ्या दृश्यत्वा" दित्यनुमाने हेतुभूतं दृश्यत्वं स्वसमानसत्ताकज्ञानविषयत्वम् दृशिस्वसमानसत्ताकत्व-निवेशाद्ब्रह्मणि नव्याभिचारः। स्वसमानसत्ताकत्वं च स्वानाशकज्ञाना-नाश्यत्वम् । तेनसत्तात्रैविद्ध्यसिद्धेर्मिथ्यात्वसिद्ध्यनन्तरभावित्वेपि नान्योन्-याश्रयः ॥

तत्र वादिनस्त्रयोदशीकक्षा । . . . . . क्षापत्तेरिष्टत्वादन्यत्र तादृश नियमो नस्वीक्रियत इति । तत्र त्रयोदशीकक्षां स्वामिनस्सभासद श्शास्त्रार्थसारग्रहणकुशलां नानुमेनिरे ॥

R. No. 5964

Paper. 10 × 5 inches. Foll. 8. Lines, 12 on a page. Devanāgarī. Injured. Extent, 200 Granthas.

Purchased in 1936–37 from P. Veṅkaṭaramaṇācāryar, Triplicane, Madras.

ब्रह्मसूत्राधिकरणार्थरत्नमाला

BRAHMASŪTRĀDHIKARAṆĀRTHARATNAMĀLĀ.

Similar to the work described under D. No. 4818.

Complete

Beginning :

ज्ञानार्थमार्थितः श्रीशो ब्रह्मरुद्रादिभिस्सुरैः ।
व्यासो भूत्वा समुत्पन्नान् व्यञ्जयन् व्यभजच्छ्रुतीः ।
तदर्थसन्निर्णयाय शास्त्रं शारीरकाह्वयम् ।
चक्रे चतुर्लक्षणेतं कलाचरणसंयुतम् ॥
शतद्वयेन विंशत्या द्वाभ्यामपि समन्वितम् ।
नयानां भूषणैस्सूत्रै स्संयुतं भगवान् प्रभुः ॥

End :

अवदन् भगवान्व्यासः श्रीशस्सज्ञानसिद्धये ।
तद्वाक्यपद्मसौरभ्यं व्यञ्जयन्मध्वमारुतः ॥
तापानपाहरत्स्वानां कृपापूरसुशीतलः ।
तुर्याध्यायतुरीयाङ्घ्रौ नया एकादशोदिताः ॥
एवं षोडशपादेषु मिलित्वा स्वररानयाः ॥

Colophon :

इति श्रीमद्ब्रह्मसुत्राधिकरणार्थरत्नमालायां चतुर्थेध्यायः ॥

R. No. 5965

Paper. 8½ × 5½ inches. Foll. 10. Lines, 19 on a page. Devanāgarī. Injured. Extent, 200 Granthas.

Purchased in 1936–37 from P. Veṅkaṭaramaṇācāryar, Triplicane, Madras.

अणुभाष्यव्याख्यानम् ।
ANUBHĀṢYA VYĀKHYĀNAM.

This is a commentary on the Brahmasūtrāṇubhāṣya of Ānandatīrtha.

Complete.

Beginning :

इन्दिरापतिमानम्य पुर्णबोधादिकान् गुरुन् ।
ब्रह्मसूत्राणुभाष्यस्य करिष्याम्यर्थसंग्रहम् ॥

अधिकारिणां ब्रह्मज्ञानसिद्ध्यर्थं वेदाः प्रवृत्ताः । तन्निर्णयाय व्यासो ब्रह्मसुत्राणि चकार । पुर्णप्रज्ञस्तेषामणुभाष्यं कर्तुं तद्गुणविशिष्टं हरिं नत्वा चिकीर्षितं प्रतिज्ञानीते—नारायणमिति ।

End :

एवं समापितभाष्यो भगवानाचार्य शिष्यशिक्षणायान्तेपि सदास्वान्तःस्थं हरिं संबोध्य क्रियासमभिव्याहारेण स्वकृतग्रन्थोक्तगुणकं प्रणमति—नमोनम इति । हे विरिंच शार्वकैरीड्य स्तुत्य अशेषदोषेभ्यो दूर हे नारायण पुर्णगुणस्वरूपदेहाय श्रीवराहाय लक्ष्मीपतये तुभ्यं नम इत्यन्वयार्थः

Colophon :

। इति श्रीमत्कृष्णद्वैपायनकृतब्रह्मसूत्राणुभाष्यव्याख्याने चतुर्थोध्यायः ।

R. No. 5966

Paper. 11¾ × 4 inches. Foll. 5. Lines, 5 on a page. Devanāgarī. Injured.

Purchased in 1936–37 from P. Veṅkaṭaramaṇāchāryar, Triplicane, Madras.

(a) तत्त्वसंख्यानम् by आनन्दतीर्थः
TATTVASAṄKHYĀNAM by Ānandatīrtha.

Foll. 1a—3b. Extent, 25 Granthas.
Same work as that described under D. No. 4788.
Incomplete.

(b) तत्त्वविवेकः by आनन्दतीर्थः
TATTVAVIVEKAḤ by Ānandatīrtha.

Foll. 4a—5a. Extent, 10 Granthas.
Same work as that described under D. No. 4785.
Incomplete.

R. No. 5967

Paper. 9 × 4½ inches. Foll. 8. Lines, 12 on a page. Devanāgarī. Injured.

Purchased in 1936-37 from P. Veṅkaṭaramaṇāchāryar, Triplicane, Madras.

(a) माण्डुक्योपनिषत्.

MĀṆḌŪKYOPANIṢAD.

Foll. 1a—2b. Extent, 40 Granthas.
Same work as that described under D. No. 694.
Complete.

(b) माण्डुक्योपनिषद्भाष्यं by आनन्दतीर्थः

MĀṆḌŪKYOPANIṢADBHĀṢYAM by Ānandatīrtha.

Foll. 3a—8a. Extent, 120 Granthas.
Same work as that described under ,D. No. 708.
Complete.

R. No. 5968

Paper. 9½ × 4½ inches. Foll. 12. Lines, 8 on a page. Devanāgarī. Injured. Extent 150 Granthas.

Purchased in 1936-37 from P. Veṅkaṭaramaṇāchāryar, Triplicane, Madras.

तलवकारखण्डार्थः

TALAVAKĀRAKHAṆḌĀRTHAḤ.

This work gives in brief the idea contained in the Talavakāropaniṣat.
Complete.

Beginning :

अथ तलवकारखण्डार्थ आरभ्यते ।
अनन्तगुणपूर्णाय दोषदूराय विष्णवे ।
नमः श्रीप्राणनाथाय भक्तेभ्योऽभीष्टदायिने ॥

अस्या उपनिषदो विरिञ्च्यात्रिसंवादरूपत्वात्तावत्र ऋषी ज्ञेयौ । देवतातु ब्रह्मशब्देन विष्णुः, छन्दस्त्वक्षरगणनया तृष्टुबादि यथायोगं ध्येयम् । जानन्नप्युमापतिर्विशेषज्ञानार्थंवा ज्ञातस्य दाढर्यार्थंवा लोकानुग्रहार्थंवा सर्वेन्द्रियप्रेरकं पृच्छति ब्रह्माणम् । इषितमिष्टं साध्व साधुवाप्रति केनदेवेन प्रेषितं सत् पतति ॥

End :

कीदृशं मन इत्यत उक्तं, अभीक्ष्णं सङ्कल्पकालगुणापरिच्छिन्ने स्वर्गे स्वरूपभूतसुखज्ञानात्मके प्रकाशरूपे ज्येष्ठे श्रेष्ठे ब्रह्मणीतियोज्यम्, प्रतिष्ठति। द्विरुक्तिस्सर्वविधारणार्थम्।

समस्तगुणपूर्णाय दोषदूराय विष्णवे।
नमः श्रीप्राणनाथाय भक्ताभीष्टप्रदायिने॥

R. No. 5969

Paper. 9 × 4½ inches. Foll. 8. Lines, 10 on a page. Devanāgarī. Injured. Extent, 130 Granthas.

Purchased in 1936–37 from P. Veṅkaṭaramaṇāchāryar, Triplicane, Madras.

तलवकारोपनिषद्भाष्यम्—सटीकम्

TALAVAKĀROPANIṢABHĀṢYAM with commentary.

Text by Ānandatīrtha.
Commentary by Vyāsatīrtha.
Same text as that described under D. No. 393.
Complete.

Beginning :

जडाजडात्मकं विश्वं कृत्वाधिष्ठाय संहरन्।
स्वभावात्क्रीडते यस्तं वन्दे मध्ववल्लभम्॥

योऽसुरानजयद्देवो हृदयस्थस्तदर्थतः।
ददौचाभीष्टमिष्टेभ्यस्तं वन्दे मध्ववल्लभम्॥

तलवकारोपनिषदं यथावद्व्याचिख्यासुर्भगवानानन्दतीर्थमुनिस्तदुक्तगुणैरुपश्लोकयन्नारायणं प्रणमति।

अनन्तेति—

End :

मङ्गलावसानस्थशास्त्रस्य प्रचयादिभावात् भाष्यं समाप्यान्तेपि स्तुतिनमनरूपं मङ्गलाचरणमाचरति * ये इति

Colophon :

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिततलवकारभाष्यटीका जयतीर्थपूज्यचरणशिष्यव्यासतीर्थविरचिता समाप्ता॥

R. No. 5970

Paper. 10¾ × 5 inches. Foll. 131. Lines, 10 on a page. Nandināgari. Injured. Extent, 2,600 Granthas.

Purchased in 1936-37 from P. Veṅkaṭaramaṇāchāryar, Triplicane, Madras.

प्रमेयदीपिकाटिप्पणी by श्रीनिवासः

PRAMEYADĪPIKĀṬIPPAṆĪ by Śrinivāsa.

This is a commentary, by Śrīnivāsa, on the Prameyadīpikā, the commentary on the Bhagavadgītābhāṣya of Ānandatīrtha by Jayatīrtha.

Contains first 4 Adhyāyas complete and 5th Adhyāya incomplete.

Beginning :

नमामि तर्काभयचक्रशङ्खपाणी सदा मध्वकरातिपूज्यौ ।
श्रीनिवासकृष्णौ परिपूर्ण बोधांस्तथा जयार्यो नितरान्गुरूंश्च ॥
वेदेशयोगिनंवन्दे यादवार्यगुरोर्गुरुम् ।
छान्दोग्यभाष्यटीकायाः कर्तारमहमादरात् ॥
अध्यात्मदर्शने रक्तान् छायानुग्रयोः पटून् ।
कृष्णनाम्नः पितन् वन्दे कृष्णपादाब्जदर्शनान् ॥
श्रीमन्न्यायसुधाया यैर्मात्र स्सम्यक् प्रकाशितः ।
तान्वन्दे यादवाचार्यान् सदाविद्यागुरूनमम ॥
अथतत्कृपया श्रीनिवासाख्यायुतसूरिणा ।
गीताभाष्यस्य टीकायाः क्रियते भावदीपिका ॥
बुधैरपि सुदुर्बोधे ग्रन्थे यन्मम साहसम् ।
तत्पारयन्तु निपुणा गुरुपादरजः कणाः ॥

अथ सर्वज्ञकल्पाष्टीकाकारा जयतीर्थश्रीमच्चरणाः श्रीमद्भगवद्गीता भाष्यं यथावद्व्याख्यातुकामाः विघ्नविघातादिप्रयोजनं स्वेष्टदेवताया लक्ष्मीपतेस्तथामूलगुरोरादिगुरोः परमगुरोः स्वगुरोश्च वन्दनरूपं मङ्गलं कृत्वा शिष्यशिक्षायै ग्रन्थादावुपनिबध्नाति—गुणगणनिलयमिति ।

End :

पुनरुक्तिरिति—सम्प्रयोगमुक्तात्मेत्यर्थः । स्तुतिरिति—स्तुतौचाधिकोक्तिरिति भावः । व्यवहितत्वादिति- क्त्वाबाहिः पदाभ्यामित्यर्थः । प्रत्याहारेण विषयोक्त्या इति शेषः । पद्विति ॥

R. No. 5971

Paper. $10\frac{3}{4} \times 4\frac{1}{4}$ inches. Foll. 30. Lines, 9 on a page. Devanāgarī. Good. Extent, 1080 Granthas.

Purchased in 1936-37 from P. Veṅkaṭaramaṇāchāryar, Triplicane, Madras.

गयामाहात्म्यम्

GAYĀMĀHĀTMYAM.

Same work as that described under R. No. 2096 with a different beginning.

Complete in 1 to 8 adhyāyas.

R. No. 5972

Paper. $10\frac{1}{4} \times 3\frac{1}{4}$ inches. Foll. 19. Lines, 7 on a page. Devanāgarī. Injured.

Purchased in 1936-37 from P. Veṅkaṭaramaṇāchāryar, Triplicane, Madras.

वासिष्ठरामायणम्

VĀSIṢṬHARĀMĀYAṆAM.

Extent, 400 Granthas.

Same work as that described under R. No. 647 (*b*).

Contains 11 to 15 adhyāyas.

R. No. 5973

Paper. $9\frac{1}{4} \times 4\frac{1}{4}$ inches. Foll. 26. Lines, 8 on a page. Devanāgarī. Injured.

Purchased in 1936-37 from P. Veṅkaṭaramaṇāchāryar, Triplicane, Madras.

वासिष्ठरामायणम्

VĀSIṢṬHARĀMĀYANAM.

Extent, 400 Granthas.

Same work as that described under R. No. 647 (*b*).

Contains 11 to 15 adhyāyas.

R. No. 5974

Paper. 8×4 inches. Foll. 16. Lines, 11 on a page. Devanāgarī. Injured.

Purchased in 1936-37 from P. Venkataramanacharyar, Triplicane, Madras.

यमकभारतटीका

YAMAKABHĀRATAṬĪKĀ.

Extant, 250 Granthas.

Same work as that described under D. No. 11890.

Contains 39 stanz as only.

R. Ro. 5975

Paper. 11 × 4¼ inches. Foll. 12. Lines, 10 on a page. Devanāgarī. Injured.

Extant, 180 Granthas.

Purchased in 1936-37 from P. Veṅkaṭaramaṇācharyar, Triplicane, Madras.

प्रमाणचन्द्रिका

PRAMĀṆACANDRIKĀ.

A work dealing with epistemology in the light of Dvaitaschool of Vedanta. The work breaks in the portion of inference.

Incomplete.

Beginning :

लक्ष्मीपतेः पदाम्भोजयुगंनत्वा गुरोरपि ।
प्रमाणचन्द्रिकां कुर्मो बालानां बोधसिद्धये ॥

इहखलु सुखमेव मे स्यादुःखं मनागपि माभूदिति निखिलापेक्षित मोक्षस्य भगवत्तदन्यस्वातन्त्र्यास्वातन्त्र्यज्ञानसाध्यत्वान्मुमुक्षूणां परतन्त्रमिदं स्वतन्त्रभगवदायत्ततया अवश्यं वेदितव्यम् ॥

End :

ज्ञातव्याप्तिकस्य कुतः कदाचिदग्निप्रमानुपपत्तिः । व्याप्तिस्मरणाभावात् । तथाच व्याप्तिस्मरणसहितं सम्यग्ज्ञातालिङ्गं समुचितदेशादावाग्नि प्रमां जनयदनुमानमित्युक्तं भवति ॥

R. No. 5976

Paper. 9¼ × 4¼ inches. Foll. 16. Lines, 13 on a page. Devanāgarī. Injured.

Extent, 383 Granthas.

Purchased in 1936-37 from P. Veṅkaṭaramaṇācharyar, Triplicane, Madras.

तत्त्वचिन्तामणिव्याख्या—सिंहव्याघ्री

TATTVACINTĀMAṆIVYĀKHYĀ—SIHMAVYĀGHRĪ.

Similar to the work described under D. No. 4073.

Contains pañcalakṣaṇī only.

Beginning :

साध्यसामानाधिकरण्यानधिकरणत्वलक्षणे यदितराधिकरणावृत्तित्वरूपा सामानाधिकरण्यं निवेश्यते, तदा द्रव्यं सत्त्वादित्यादावतिव्याप्तिः ; सत्ताया-द्रव्यत्वाधिकरणवृत्तितया तादृशसामानाधिकरण्यानधिकरणत्वात् ॥

End :

स्वनिष्ठहेतुतावच्छेदसम्बन्धावच्छिन्नवृत्त्यनवच्छिन्नहेतुतावेच्छेदकसम्बन्धा वच्छिन्नसाध्यसामानाधिकरण्याभावकत्वम् , विवक्षणीयमित्यादयः परिष्कारस्य पन्थानो द्रष्टव्याः ॥

Colophon :

सिद्धव्याप्तिस्समाप्ता ॥

R. No. 5977

Palm leaf. 12¼ × 1½ inches. Foll. 28. Lines, 8 in a page. Nandināgari. Injured.

Purchased in 1936-37 from P. Veṅkaṭaramanācharyar, Triplicane, Madras.

(a) सत्तत्त्वरत्नमालिका by आनन्दतीर्थः

SATTATTVARATNAMĀLIKĀ by Ānandatīrtha.

Foll. 1 a-24 b. Extent, 380 Granthas.
Same work as that described under D. No. 4844.
Complete.

(b) भळित्थेत्यादिसूक्तार्थः

BHAḶITTHETYĀDISŪKTĀRTHAḤ.

Foll. 25a—28b. Extent, 50 Granthas.
This contains an explanation of the sūkta Bhaḷittha as refering to Vādirāja.
Incomplete.

Beginning :

भळित्थेत्यादिसूक्तस्य श्रीमल्लातव्याचार्यावतारभूतश्रीमद्वादिराज भगव-त्पान्तयार्थमाह । तथाहि ।

सहोरूपस्य देवस्य लातव्यस्य बलात्मकम् ।
मूलरूपं ज्ञाततं जगद्वरणजं यतः ॥
जातं तेनात्मकं सर्ववेष्टकेन महात्मना ।
रूपत्रयावताराय निहितं हरिणा स्वयम् ॥

End :

जगद्द्वयं तु सृष्ट्वादौ भगवान्पुरुषोत्तमः ।
स्वोदरे संस्थिता न्मिश्रान्स्थापयित्वा प्रभुः स्वयम् ॥
" ततस्सृष्टिं चकारासौ भगवान्पुरुषोत्तमः "
इति प्रमाणसंग्रहे ॥

R. No. 5978

Palm leaf. 16 × 1 inches. Foll. 39. Lines, 4 on a page. Nandinâgari. Injured.

Purchased in 1936-37 from P. Veṅkaṭaramanāchayar, Triplicane, Madras.

पिनाकिनीमाहात्म्यम्

PINĀKINĪMĀHĀTMYAM.

Foll. 1a—39a. Extent, 315 Granthas.

Same work as that described under D. No. 2466.

Complete.

R. No. 5979

Palm leaf. 16 × 1½ inches. Foll. 142. Lines, 6 on a page. Nandinâgari. Injured.

Purchased in 1936-37 from Śrī P. Veṅkaṭaramanāchariyar, Triplicane, Madras.

(a) काण्वोपनिषदर्थसंग्रहः by राघवेन्द्रयतिः

KĀṆVOPANIṢADARTHASAṄGRAHAḤ by Rāghavendrayati.

Foll. 1a—125a. Extent, 2,000 Granthas.

This work gives in brief the idea contained in the Kāṇvopaniṣat.

Complete.

Beginning :

प्रणम्य श्रीमदानन्दतीर्थादिगुरुशेखरान् ।
काण्वोपनिषदोऽर्थानां संग्रहः क्रियते मया ॥

अस्या उपनिषदो ब्रह्मसूर्ययाज्ञवल्क्याकाण्वाः क्रमादृषयः । लक्ष्मीशो देवता । वाक्यरूपत्वान्नच्छन्दोऽन्वेषणम् । अस्या उपनिषदोऽध्यायाष्टकात्मकत्वेपि पूर्वाध्यायद्वयस्य विद्याधिकारार्थ मश्वमेधकर्मनिरूपणपरत्वेन तदव्याख्याय कर्मणा शुद्धान्तःकरणस्य ब्रह्मस्वरूपं निरुपयितुं

प्रवृत्तं वृत्तीयाध्यायादिग्रन्थसन्दर्भं व्याचख्यौ भगवान्भाष्यकारः । तथाहि-आदौ पूर्वप्रकृताश्वमेधयागीयाश्वनिष्ठां ब्रह्मविद्यामाह—उषावा इत्यादिना.

End :

अध्यायद्वयोक्तविद्याप्रवर्तकपरम्परां प्रस्तावपूर्वकमाह—अथवंश इत्यादिना । अत्रपञ्चम्यन्तादुपदेष्टारः, प्रथमान्तादुपदेश्या ज्ञेयाः । ....
इत्यष्टमोऽध्यायः

Colophon :

इति श्रीकाण्वोपनिषदो भाष्यायुक्तार्थसंग्रहः ।
श्रीराघवेन्द्रयतिना कृतस्सज्जनसंविदे ॥

(b) छान्दोग्योपनिषद्व्याख्या.
CHĀNDOGYOPANIṢADVYĀKHYĀ.

Foll. 126a—140b. Extent, 250 Granthas.
Similar to the work described under R. No. 77.
Contains sixth Adhyāya only.

Beginning :

श्वेतकेतुर्नामतः, आरुणेयो अरुणस्य पौत्रः, अरुणाया पुत्र इतिवा आसह । तंह पिता गुरुरुद्दालक उवाचहकिल । किमिति । हेश्वेतकेतो वस ब्रह्मचर्यं, वेदाध्ययनार्थं गुरुकुलवासं कुर्वित्यर्थः

End :

भूतानि सर्वभूतान्तर्गतानि भगवद्रूपाणि पूर्णानि वा सम्यक्पश्यतः परोक्षीकुर्वतो मार्गपदज्ञानात् भगवत्स्वरूपज्ञानात् पदैषिणः स्वपदपतीच्छवो देवाअपि मुह्यन्ति । देवैरप्याकां .... इति श्रुतिरियम् । द्विर्वचनमध्यायस्य सर्वस्यापि प्रामाणिकत्वसूचनार्थम्

Colophon :

इति श्रीमच्छान्दोग्योपनिषद्व्याख्याने षष्ठोऽध्यायः ।

R. No. 5980

Palm leaf. 15¾ × 1¼ inches. Fol. 190. Lines, 7 on a page. Nandināgarī. Injured. Extent, 5,320 Granthas.

Purchased in 1936-37 from Śrī P. Veṅkaṭaramaṇācāriar, Triplicane, Madras.

ब्रह्मसूत्रभाष्यटीका—तत्त्वप्रदीपिका by त्रिविक्रम

BRAHMASŪTRABHĀṢYAṬĪKĀ—TATTVAPRADĪPIKĀ by Trivikrama.

Similar to the work described under D. No. 4813.
Complete.

Beginning :

पूर्णज्ञानं विपुलपरमानन्दसन्दोहदेहं
भक्तप्रोक्ताकृतविवरणब्रह्मसूत्राव . . . . .
. . न्नारायण पदमहं ध्वस्तनिश्शेषदोषं
वन्दे नित्यं गुरुमपि गुरोरागमार्थप्रकाशम् ॥
यस्याम्नायपदाक्षराणि परमं स्वार्थं लभन्ते गुणान्
संप्रोच्यैव हितानि वलव . . . . तिसासादिभिः ।
तं सेव्यं मुनिभिः प्रशान्तमनसा भक्त्या भवच्छिन्तये
स्वानन्दप्रद मिन्दिरापतिमहं भूयोऽभिवन्दे हरिम् ॥

Colophon :

इति श्रीमदानन्दतीर्थभगवत्पादविरचितस्य श्रीमद्ब्रह्मसूत्रभाष्यस्य टीकायां त्रिविक्रमार्यकृतौ तत्त्वप्रदीपिकायां प्रथमाध्यायस्य प्रथमः पादः

End :

नमस्तस्मै नमस्तस्मै समस्तस्वामिनेऽस्तु ते ।
नमस्तस्मै च यस्तस्मै नमस्कर्ता गुरुः सदा ॥

Colophon :

इति श्रीमदानन्दतीर्थभगवत्पादविरचितस्य श्रीमद्ब्रह्मसूत्रभाष्यस्य टीकायां त्रिविक्रमार्यकृतौ तत्त्वप्रदीपिकायां चतुर्थाध्यायस्य चतुर्थः । चतुर्थाध्यायः समाप्तः ।

R. No 5981

Palm leaf. 17 × 1¾ inches. Foll. 71. Lines, 6 on a page. Nandināgarī. Injured.

Purchased in 1936-37 from Śrī P. Veṅkaṭaramaṇācariar, Triplicane, Madras.

(a) पदार्थसंग्रहः

PADĀRTHASAṄGRAHAḤ.

Foll. 1—15. Extent, 360 Granthas.

Similar to the work described under D. No. 15717.

Complete.

Beginning :

प्रणम्य रामचन्द्राङ्घ्रिं दश प्रमितिपूर्वकान् ।
संगृह्यन्ते पदार्थाश्च दश प्रमितिवर्त्मना ॥

तत्र प्रमितिविषयाः पदार्थाः । तेऽष्टविधाः । द्रव्यगुणकर्मसामान्य विशेष विशिष्टांस्य (?) भावभेदात् । द्रव्यत्वाद्येव द्रव्यादीनां लक्षणम् ।

End :

पदार्थानां विवेकोऽयं संग्रहेण निरूपितः ।
धार्यतां हृदये सद्भिः साधवो हि गुणग्रहाः ॥

Colophon :

इति श्रीपदार्थसंग्रहः समाप्तः ।

(b) पदार्थसंग्रहः

PADĀRTHASAṄGRAHAḤ.

Foll. 17—71. Extent, 1,296.

Similar to the work described under D. No. 15717.

Contains the end of Dravyapariccheda.

Beginning :

जानकी वदनांभोजभानवे गतये सताम् ।
नमः श्रीरामचन्द्राय हेतवे सर्वसंपदाम् ॥

सृष्टिरक्षाहृतिज्ञाननियत्यज्ञानबन्धनात् ।
मोक्षं च विष्णुतश्चैव ज्ञात्वा मुक्तिर्नचान्यथा ॥

End :

तेषां वेदबाह्यत्वात् । द्यावाभू . . . . न् दव एक इत्यादि-श्रुते श्चात्रानुसन्धेया ॥ इति संक्षेपः ।

Colophon :

इति परमात्मविवेकः । इति श्रीपदार्थसंग्रहे द्रव्यपरिच्छेदः समाप्तः ।

R. No. 5982

Palm leaf. 16¼ × 1½ inches. Foll. 86. Lines, 9 on a page. Nandināgarī. Injured.

Purchased in 1936-37 from Śrī P. Veṅkaṭaramaṇācariar, Triplicane, Madras.

(a) मन्त्रार्थमञ्जरी by राघवेन्द्रयतिः

MANTRĀRTHAMAÑJARĪ by Rāghavendrayati.

Foll. 1a—84a. Extent, 3024 Granthas.

This work gives in brief the summary of the hymns which were explained in the Ṛgbhāṣya of Ānandatīrtha.

Contains the end of 2nd Varga of 8th Sūkta.

Beginning :

अशेषगुणसंपूर्णं सर्वदोषविवर्जितम् ।
अनन्ताम्नायसंवेद्यं वन्देऽहं कमलापतिम् ॥
प्रणम्य श्रीमदानन्दतीर्थादिगुरुशेखरान् ।
संग्रहिष्यामि ऋग्भाष्यप्रोक्तानर्था नृचां स्फुटम् ।

* * * *

सहोतेतिश्रुत्या होतृनियामकतया विशिष्य तत्रसान्निध्यात् तदधीनत्वादिति प्रागुक्तन्यायेनैव होतृनामकमृत्विजं होतारमिति कुरुपाण्डवन्यायेनैव समान्यविशेषभावादपुनरुक्तिः ।

Colophon :

इति श्रीमन्त्रार्थमञ्जर्यामाद्यमाग्नेयम् ।

* * * *

इति श्रीमन्त्रार्थमञ्जर्यां राघवेन्द्रयतिकृतायां सप्तमे सूक्ते द्वितीयो वर्गः ।

* * * *

इति मन्त्रार्थसंग्रहे द्वितीयो वर्गः ।

End :

कल्याणगुणपूर्णाय दोषदूराय विष्णवे ।
अनन्ताम्नाय वेद्याय श्रीप्राणपतये नमः ॥

Colophon :

इति श्रीसुधीन्द्रगुरुपादशिष्यराघवेन्द्रयतिकृतायां मन्त्रार्थमञ्जर्यां अष्टमेसूक्ते द्वितीयो वर्गः ॥

(b) ऋग्भाष्यटीकाव्याख्या by रामचन्द्रतीर्थः

ṚGBHĀṢYAṬĪKĀVYĀKHYĀ by Rāmacandratīrtha.

Foll. 84b—86. Extent, 72 Granthas.

This work is a commentary, by Rāmacandratīrtha, on the Ṛgbhāṣya-ṭīkā.

Incomplete.

Beginning :

कल्याणगुणपूर्णाय कञ्जजादिप्रसूतये ।
श्री मध्वदेशिकेष्टाय श्रीवराहाय ते नमः ॥

अशेषप्राणिनां ने श्रा(त्रा)येनसंपूज्यते हरिः ।
तस्य वायोस्तृतीयं तद्रूपं मध्वाभिधंभजे ॥

मूकोपि वाग्मितां यायात् यदनुग्रहमात्रतः ।
सेवेतं जययोगीन्द्रं प्रतिवादिमतच्छिदम् ॥

यस्तत्वं विषलाः सर्वे पीत्वा न्यायामृतं मुदा ।
अमंस त तृणायारीन् व्यासतीर्थं तमाश्रये ॥

अस्त्यतः शास्त्रवासेन रामचन्द्राख्यभिक्षुणा ।
ऋग्भाष्यविवृतेर्व्याख्या क्रियते प्रीतये हरेः ॥

End :

यद्यपि होतृशब्दस्य तृजन्तत्वेपि कर्तरिचेत्यत्र कृद्योगलक्षणाया एव षष्ट्याः समासप्रतिषेधात् । शेषलक्षणषष्ठ्याः समासोपपत्तिस्तथाप्यृग्शब्दित विश्वनियन्तृविष्णोः स्वभाव एव । नतुप्रयोजनोद्देशेनेति ज्ञापयितुं ताच्छीलिकतृजन्तताश्रितेति ध्येयम् ॥

R. No. 5983

Palm leaf. 9¼ × 2 inches. Foll. 76. Lines, 9 on a page. Nandināgarī. Injured.

Purchased in 1936–37 from Śrī P. Veṅkaṭaramaṇācāriar, Triplicane Madras.

(*a*) प्रमाणपद्धतिव्याख्या

PRAMĀṆAPADDHATIVYĀKHYĀ.

Foll. 1*a*—31*b*. Extent, 900 Granthas.

Similar to the work described under D. No. 4805.

Incomplete.

पद्मापतिपदांभोजयुग्ममानम्य सद्गुरून् ।
प्रमाणपद्धतेर्भावं वर्णयामि यथामति ॥

प्रारिप्सितस्य ग्रन्थस्य निर्विघ्नेन परिसमाप्त्यर्थं कृतं नमस्काररूपं मङ्गलं शिष्यशिक्षार्थं निबध्नन् चिकीर्षितं प्रतिजानीते । प्रणम्येति ।

End :

एते पदार्था वा तात्पर्यविषयाभिधसंसर्गवन्तः आकांक्षादिमत्पदस्मारितत्वात् इत्येवमनुमानेन वक्तृज्ञा . . . .

b प्रमाणलक्षणटीकाव्याख्या by विजयीन्द्रभिक्षुः

PRAMĀṆALAKṢAṆAṬĪKĀVYĀKHYĀ by Vijayīndrabhikṣu.

Foll. 32—76. Extent, 1,188 Granthas.

This is a commentary, by Vijayīndrabhikṣu, on the Pramāṇalakṣaṇaṭīkā of Jayatīrtha.

Incomplete.

Beginning :

सर्वज्ञं सर्वकर्तारं सर्वजीवजडात्मकम् ।
प्रपञ्चाद्वस्तुतोऽनन्यं भिन्नं नरहरिं भजे ॥

Colophon :

इति श्रीविजयीन्द्रविरचितायां प्रमाणपद्धतिटीकायां द्वितीयंप्रकरणम् ।

End :

न्यूनाधिकभावस्याशक्याज्ञानत्वेन अयोगात् । घटवति घटोपलंभे घटाभावरूपाविशेषणीभावेनैव घटाभावप्रमानुत्पत्तेरुपपत्तेः ॥

* * * *

R. No. 5984

Paper, 9¾ × 4¼ inches. Foll. 47. Lines, 13 on a page. Devanāgarī. Injured. Extent, 1000 Granthas.

Purchased in 1936-37 from Śrī P. Veṅkaṭaramaṇācāryar, Triplicane, Madras.

तत्त्वचिन्तामणिदीधितिप्रकाशिका by गदाधरः

TATTVACINTĀMAṆIDĪDHITIPRAKĀŚIKĀ by Gadādhara.

Same work as that described under D. No. 4046.

Contains Sāmānyanirukti complete.

R. No. 5985

Paper. 9¼ × 4½ inches. Foll. 8. Lines, 13 on a page. Devanāgarī. Injured. Extent, 200 Granthas.

Purchased in 1936-37 from Śrī P. Veṅkaṭaramaṇācaryar, Triplicane, Madras.

तत्त्वचिन्तामणिदीधितिः

TATTVACINTĀMAṆIDĪDHITIḤ.

Same work as that described under D. No. 4012.

Contains caturdaśalakṣaṇī and Pañcalakṣaṇī.

R. No. 5986

Paper. 9 × 4½ inches. Foll. 4. Lines, 13 on a page. Devanāgarī. Injured. Extent, 100 Granthas.

Purchased in 1936-37 from Śrī P. Venkataramanacāryar, Triplicane, Madras.

तत्त्वचिन्तामणिदीधितिः

TATTVACINTĀMAṆIDĪDHITIḤ.

Same work as that described under D. No. 4006.

Contains Sāmānyanirukti incomplete.

R. No. 5987

Paper. 9 × 4½ inches. Foll. 123. Lines, 13 on a page. Devanāgarī. Injured. Extent, 2500 Granthas.

Purchased in 1936-37 from Śrī P. Veṅkaṭaramaṇācāryar, Triplicane, Madras.

तत्त्वचिन्तामणिदीधितिप्रकाशः by गदाधरः

TATTVACINTĀMAṆIDĪDHITIPRAKĀŚAḤ by Gadādhara.

Same work as that described under D. No. 4053.

Contains caturdaśalakṣaṇī incomplete.

R. No. 5988

Paper. 9¼ × 4½ inches. Foll. 7. Lines, 12 on a page. Devanāgarī. Injured. Extent, 140 Granthas.

Purchased in 1936-37 from Śrī P. Veṅkaṭaramaṇācāryar, Triplicane, Madras.

गदाधरीयव्याख्या by शङ्करभट्टः
GADĀDHARĪYAVYĀKHYĀ by Śaṅkarabhaṭṭa.

Same work as that described under D. No. 4083.
Incomplete.

R. No. 5989

Paper. 9½ × 4½ inches. Foll. 9. Lines, 10 on a page. Devanagari. Injured. Extent, 170 Granthas.

Purchased in 1936-37 from Śrī P. Veṅkaṭaramaṇācāryar, Triplicane, Madras.

प्रामाण्यवादः
PRĀMĀṆYAVĀDAḤ.

Similar to the work described under R. No. 113 (*b*).
Wants beginning.
Contains jñaptiprāmāṇyavāda complete.

Beginning :

सिद्धान्तरु . . . . प्रामाण्यस्य स्वतोग्रहेप्यनभ्यासदशापन्नज्ञाने तत्संशयो नस्यात् । ज्ञानग्रहे प्रामाण्यनिश्चयादनिश्चयेवा स्वतो नप्रामाण्यग्रहः । ज्ञानाग्रहे धर्मिज्ञानाभावान्नसंशयः ॥

End :

लिङ्गादिनिश्चयस्य स्वकारणाधीनस्य सर्वसिद्धत्वादितिचेन्न । प्रामाण्य संशयेन लिङ्गस्य सन्देहात् । नहि लिङ्गादिज्ञानेन प्रामाण्यस्य संशयः अनुभवविरोधादिति । उच्यते । अप्रामाण्यशङ्काकलङ्काभावेन लिङ्गादि ज्ञानस्यैवार्थनिश्चायकत्वात् । तत्क . . . . केतुक्तैवगतिः । यत्तुव्यवसायेकचिदप्रामाण्यशङ्का कचिद्वर्तत इति ॥

* * * *

तदुक्तम्

नहि पिपासूनां झटिति प्रचुरतरा समर्था च प्रवृत्ति . . . . सीति पिपासोपशमनशक्तिः प्रत्यक्षेति ।

Colophon :

इति ज्ञप्तिप्रामाण्यवादः

R. No. 5990

Paper. 10 × 5½ inches. Foll. 41. Lines, 15 on a page. Telugu. Slightly injured. Extent, 1000 Granthas.

Purchased in 1936-37 from Śrī P. Veṅkaṭaramaṇācāryar, Triplicane, Madras.

कल्पलताबन्धः—सव्याख्यः by मुद्दुकविः

KALPALATĀBANDHAḤ with commentary by Muddukavi.

A Kāvya by Maddukavi addressed to a king Mukunda by name. This work contains a commentary. The author of which is not known.

Contains Stabakas 1—3 complete. 58 stanzas in the 4th Stabaka.

Beginning :

(मू.) श्रीराजाने यशस्विन् प्रभवतु नृविभो मोददाता मुकुन्द
स्वावस्थायासमानो भुवि जय . . . राराशिजारं दुरापः ।
त्वां सेनान्यं महस्विन् ददुदयपरमानन्दवन्देकलार्कं
कुंजेतारं रेम . . . वि विलसन्मानया . . विधेयम् ॥

(व्या) श्रीति । इराभूमिः जायायस्येराजानिः जायायानिःश्रीयुतश्चासौ इराजानिश्चेति कर्मधारयसमासः । शाकपार्थिववत् । हे श्रीराजाने नृपते "इराभूवाक्सुराप्सुस्यादित्यमरः ।

* * * *

मुद्दुकविविजयदप्रभुवरविभ्रमवप्रभोविभान्वविभो ।
भोराजासन् सा भायागो भोमोददातारम् ॥

Colophon :

इति कल्पलताबन्धे गजाश्मपुरवासिमुद्दुकविकलिते ।
बहुविधवृत्तविचित्रे प्रथमस्तबकोऽस्तु सुमनसां प्रीत्यै ॥

End :

मोमुदिनसन्तुष्टत प्रतापः जयश्शत्रुजयः भगः कीर्तिश्चलसाति ।
त्वं भ्राज प्रकाशमानो भव ।

* * * *

(व्या) भासाधीना . . . . नुरमण भयोधीशभूतं विधेयं . . .
. . . . श्र्यायस्या महात्मा तनुविभवा राज्ञावन् किलार्कम्

* * * *

R. No. 5991

Paper. 12 × 4 inches. Foll. 9. Lines 10 on a page. Devanāgarī. Injured. Extent, 160 Granthas.

Purchased in 1936-37 from Śrī P. Veṅkaṭaramaṇācāryar, Triplicane, Madras.

गङ्गालहरी—सव्याख्या

GAṄGĀLAHARĪ with commentary.

Same text as that described under R. No. 5550.

Complete.

Beginning :

इह कर्मज्ञानादिभिरनुकंपासंपादनेन कंसारेस्संसारतरणाकल्पानल्पाभिरीप्स्य शरणागतकरुणावशा यतयोऽमितमतयो ऽधुनाधरित्रागतानां पवित्रीकरणाय वसुमतीविरचितावतरणायाः परमपुरुषचरणाभरणायाः निजमज्जनेन सज्जनानां प्राचीनदुरितदूरीकरणधुरंधरायाः गङ्गायाः कांचन लहरीमन्ते एव स्वान्त स्फुरद्धारिपदानुबन्धामति शुद्धां वन्वाना मन्वानास्तस्याः पठनायः (?) विघटनायाः विना निबन्धं जना नबन्धं त्यजन्तीतिता निबध्नन्ति ॥ जले इत्यादिना

End :

स्वभावमधुरा गङ्गालहरी गुरुभिःकृता ।
तन्माधुरी तट्टीका लिखिता तन्निदेशतः ॥
सरसां लहरीमेतां सेवन्ते येत्र सज्जनाः ।
तन्मांधुरी (?) न सज्जेयुस्सरसग्राहिणो यतः ॥

* * * *

अतधर्मेयतीमत्वा ज्ञात्वातन्मुखतोमया ।
तत्कृता लहरीव्याख्या विशिष्टाक्रियते सती ॥

R. No. 5992

Palm leaf. 15¾ × 2 inches. Foll. 12. Lines, 8 in a page. Nandināgarī. Injured.

Purchased in 1936-37 from Śrī P. Veṅkaṭaramaṇācāryar, Triplicane, Madras.

(a) नृसिंहस्तुतिः by नारायणपण्डितः

NṚSIṀHASTUTIḤ by Nārāyaṇapaṇḍita, son of Likucatilaka.

Foll. 1a—7b. Extent, 225 Granthas.

Same work as that described under D. No. 10101.

Complete.

(b) विष्णुस्तुतिः

VIṢṆUSTUTIḤ.

Foll. 8a—9a. Extent, 40 Granthas.

Similar to the work described under D. No. 10353.

This is a portion of the Pāñcarātrāgama.

Complete.

Beginning :

उषासि चिन्तये द्विष्णुं भोजने च जनार्दनम् ।
शयने पद्मनाभं च स्त्रीसङ्गे पुरुषोत्तमम् ॥
संग्रामे चक्रपाणिं च प्रवेशे च त्रिविक्रमम् ।
दुःस्वप्ने स्मर गोविन्दं भये च मधुसूदनम् ॥

End :

एवं सर्वपदार्थेषु घटादिषु च वस्तुषु ।
तत्तदाकारसंस्थस्तु तत्तन्नामाभिधो हरिः ।
एवं चिन्त्यस्सदा विष्णु र्मोक्षकामै र्न संशयः ॥
अज्ञात्वा भगवद्रूपं यः कर्म कुरुते नरः ।
तस्य कर्म वृथा याति गजभुक्तकपित्थवत् ॥

Colophon :

इति पाञ्चरात्रागमस्संपूर्णः

(c) शिवस्तुतिः by नारायणपण्डित

ŚIVASTUTIḤ by Nārāyaṇapaṇḍita.

Foll. 9b—10b. Extent, 35 Granthas.

Similar to the work described under D. No. 11222.

Complete.

Beginning :

स्फुटं स्फटिकसप्रभं स्फुटितनाटकश्रीजटं
शशाङ्कदलशेखरं कपिलफुल्लनेत्रत्रयम् ।
तरक्षुवरकृत्तिमद्भुजगभूषणं भूतिमत्
कदा नु शितिकण्ठ ते वपुरवेक्ष्यते वीक्षणम् ॥

End :

सतां श्रवणपद्धतिं (सरतु) स्वदतु सन्नतोन्नत्यसौ
शिवस्य करुणाङ्कुरान्प्रति कृता सदा सोदिता ।
इति प्रयतमानसां व्यधित नाम नारायणः
शिवस्तुति मिमां शुभां लिकुचसूरिसूनुः सुधीः ।

Colophon :

॥ नारायणपण्डितार्यविरचिता शिवस्तुति स्संपूर्णा ॥

(*d*) विष्णुपारम्यनिरूपणम्

VIṢṆUPĀRAMYANIRŪPAṆAM.

Foll. 11*a*—12*a*. Foll. 12*b* is left blank. Extent, 35 Granthas. Similar to the work described under R. No. 3524. Incomplete.

Beginning :

वायो राज्ञीं पुरस्कृत्य मणिभद्रः प्रचोदितः ।
मध्वगेहस्य भार्यायां प्रवेशं कृतवान्प्रभुः ॥
. . .
नवमासावसाने तु स्वयं गत्वा बलात्मकः ।
बहिर्निष्कासयामास तं जातं तु तदैवहि ।

* * * *

नन्वत्र प्रयोगप्रकारः कथं:— इति चेदुच्यते । ब्रह्ममीमांसा शास्त्रं, विष्णूत्कर्षरूपतत्त्वनिर्णायकं, आनन्दतीर्थवत्त्वात्, भारतवादिति ।

End :

उपदेश्यतया आनन्दतीर्थवत्त्वात्, भारतवदिति निर्णयसाध्यक एव प्रयोगप्रकारः । भारतादौ सपक्षे निर्णयवत्त्वं च जनकतया . . . . . . ध्यविकल्पम् । अन्यत्स्पष्टम् ।

R. No. 5993

Palm leaf. 13 × 1¼ inches. Foll. 71. Lines, 5 in a page. Nandināgarī. Injured.

Purchased in 1936-37 from Śrī P. Veṅkaṭaramaṇācāryar, Triplicane, Madras.

(a) पञ्चसूक्तम्
PAÑCASŪKTAM.

Foll. 1a—57a. Foll. 57b is left blank. Extent, 1,200 Granthas.

Contains Viṣṇusūktam, Gharmasūktam, Samudrasūktam, Puruṣasūktam, Manyusūktam.

Same work as that described under D. No. 228.

(b) विष्णुसहस्रनामस्तोत्रम्
VIṢṆUSAHASRANĀMASTOTRAM.

Foll. 58a—69b. Extent, 240 Granthas. Printed.
Same work as that described under D. No. 9008.
Complete.

(c) मङ्गलाष्टकम् by वादिराजः
MAṄGALĀṢṬAKAM by Vādirāja.

Foll. 70a—71b. Extent, 40 Granthas.
Same work as that described under D. No. 10183.
Complete.

R. No. 5994

Palm leaf. 11¾ × 1½ inches. Foll. 30. Lines, 5 in a page. Nandināgarī. Injured. Extent, 450 Granthas.

Purchased in 1936-37 from Śrī P. Veṅkaṭaramaṇācāryar, Triplicane, Madras.

तिथ्यादिनिर्णयः
TITHYĀDINIRṆAYAḤ.

Similar to the work described under D. No. 3120.
Incomplete.

Beginning :

श्रावण शुक्लपौर्णमी, उपाकर्मपरदिने पौर्णमी 12 घटिका चेत् परदिने । उपाकर्मप्रतिपादिने द्वादशघटिकायाः परं चेत्पूर्वदिने उपाकर्म । ऋग्वेदिनां श्रवणं श्रवणनक्षत्रे

* * * *

अथ संक्रान्तयो द्वादश । तत्रमेषतुलयोः पूर्वोत्तरभागयोः दश घटिकाः पूर्वकालः ।

* * * *

अथ ग्रहणे पूर्वरात्रौ चन्द्रग्रहणे . . . . अहर्भोजनं नकार्यम्। सार्धप्रहरमध्यमोक्षश्चेत् राहुमुक्तचन्द्रं दृष्ट्वा स्नात्वा ताम्बूलादिकं गृ)ह्णीया)त् प्रथमयामग्रहणे तु अहर्भोजनं कार्यम् ।

* * * *

आर्यमानेन दशमीगणनप्रकारः ।
भोगोद्रेरदारैः हीनो दांषोऽङ्कुरः शतान्वितः ।
पलेनापि समायुक्ता तिथिः सा सर्पसंमता ॥
अस्यार्थः नवमीप्रविष्टदशमीघटिकासमुदायः ।

* * * *

अरुणोदयवेलायां दशमी परिदृश्यते इत्यादिना विष्ण्वेकादशी त्याज्येत्युक्तम् ।

End :

द्वादश द्वादशी हन्ति पूर्वेद्युः पारणे कृते ।
एकादश्यां तु विद्धायां परतो द्वादशी यदि ॥

" उपवासद्वयं कार्यं " इत्यादिवचननिचयमनुसृत्य . . . . . .

R. No. 5995

Paper. 12 × 4 inches. Foll. 2. Lines, 6 on a page. Devanāgarī. Injured. Extent, 25 Granthas.

Purchased in 1936–37 from Śrī P. Veṅkaṭaramaṇācāryar, Triplicane, Madras.

पञ्चावयववाक्यलक्षणम् ।

PAÑCĀVAYAVAVĀKYALAKṢAṆAM.

This work gives the definitions of the statements of the five syllogisms according to the Nyāya system.

Complete.

Beginning :

तच्चानुमानं परार्थेन्यायः, तदवयवाश्च प्रतिज्ञाहेतूदाहरणोपनयनानि निरूप्यन्ते । तत्रसमस्तरूपोपपन्न + न्यायसाध्यमिति + लिङ्गप्रतिपादकवाक्यं न न्यायः । तत्रैव वाक्येऽतिव्याप्तेः । किन्त्वनुमितिचरमकारणीभूतलिङ्गपरामर्शजनकशाब्दज्ञानजनकवाक्यं न्यायः ॥

End :

अवयवत्वंतु न्यायान्तर्गतत्वेसति प्रतिज्ञाद्यन्यतमत्वं, प्रतिज्ञाद्यघटकत्वे सति उभयघटकभागद्वयाघटितत्वं वा वक्तव्यम् ।

R. No. 5996

Palm leaf. 16 × 1 inches. Foll. Lines, 7 in a page. Grantha. Injured.

Purchased in 1936–37 from Śrī K. Rangasami Iyengar Al, South Siruvalur, Tindivanam taluk.

(a) अम्बास्तवव्याख्या by अर्धनारीश्वरदीक्षितः

AMBĀSTAVAVYĀKHYĀ by Ardhanariśvara Dikṣita.

Foll. 1a—57b. Extent, 1325 Granthas.

This work is a commentary, by Ardhanārīśvara Dikṣita, on the text, similar to that described under D. No. 9570.

Complete.

Beginning :

. . . . पद्येषु ब्रह्मविद्यया ।
प्राणत्त्वरणभूषाय परस्मै ब्रह्मणे नमः ॥

घ्राणायुकरबाणानां रसनाजीवन निदानचापल . . ।
. . . . प्राणकलां नौमि पश्चमकुटस्य ॥

हरिहरयोरवताराबाकलये व्यासशङ्करौ हृदये ।
उदधारि कुमतिशङ्कापङ्कातङ्का जग . . . . ।

कपिलकणादजैमिनिपराशरभूफणिराट्, पदनयनेन्द्रदेशिकजिनादि-मदोद्यतधीः । पशुपतिपाञ्चरात्रगणनाथ कुमारशिवागममहित स्सरत्न-फलकाध्वरिराट् जयति ॥

श्रीश्रीनिवासमखिनस्तस्य पुत्रो महायशाः ।
तस्मादधीत्य शास्त्राणि सर्वाण्येतानि सद्गुरोः ॥

कामाक्षीतनयः श्रीमानर्धनारीश्वरस्सुधीः ।
अम्बास्तवस्य व्याख्यानं कुरुते गुरुसंमतम् ।

स्खलितं मतिदौर्बल्यादस्तिचेदत्रमे क्वचित् ।
समीकुरुत विद्वांसो गुणीकरण . . . ।

(श्री)शङ्कराचार्यकृतौ प्रबन्धौ
सौभाग्यविद्यासुभगोदयाख्यौ ।
पुनः पुनस्साधु विचिन्त्य बुध्या
तद्व्याख्यनाहं करवै निबन्धम् ॥

इति खलु कालिदास . . . . महाकविः सर्वमङ्गलाप्रसादलब्ध सर्वविद्याधिपत्यस्तामेव सर्वमङ्गलामेकत्रिंशच्छ्लोकैरभिष्टौति — यामामनन्तीति ।

End :

तदनेन न्यायेन प्रतिकामं स्तुत्यावृत्तौ गौरवं तर्कयन् सर्वज्ञशिखामणिरसौ सकृदेव सर्वफलसाधकं सर्वेश्वरीसान्निध्यं प्रार्थयमानस्तस्मिश्च नैरन्तर्यं तमेवैकं जानथ आत्मानमन्या वाचो विमुञ्चथेति श्रुत्या निरन्तरब्रह्मसाक्षात्कारस्याभिहितत्वात् निर्गुणब्रह्माभिन्नस्यात्मप्रत्यभिज्ञानस्य च सगुणब्रह्मसाक्षात्काराधीनत्वात्तमेव साक्षात्कारं निरन्तरं प्रार्थयते ।

Colophon :

इति विश्वामित्रगोत्ररत्नाकरसुधाकरेण श्रीभवस्वामिभाष्यकर्तु भवस्वामि सर्वतोमुखयाजिनः सप्तमेनानवरतान्नदानिनः प्रतिदिनप्रबन्धपरमेश्वरस्य कृष्णसोमपीथिनः षष्ठेनाद्वैतचिन्तामणिकर्तुः कुमारभवस्वामिमहाव्रतयाजिनः पञ्चमेन श्रीकृष्णचरणारविन्दपरिचरषट्चरणायमानान्तःकरणस्य कृष्णसोमयज्वनो नप्त्रा वैकुण्ठाणघण्टामणेः (?) परमभागवतस्य भवस्वामिभट्टस्य पौत्रेण श्रीकेशवपरिचरणचणचरणारविन्दपरिचरणलब्धसर्वविद्याधिपत्यस्यार्धनारीश्वरवामभागस्तन्यपरिवर्धितस्य मत्तमदावलमस्तकन्यस्तदिवाप्रदीपघोषणस्य समस्तविरुदवाद्यनिनदसङ्कुचितरोदःकटाहस्य प्रतिनृपतिसभं पत्रालम्बनकारकस्य प्रतिभटविद्वज्जनविजयतोषितराजन्यपारितोषिकलब्धचरणकटकठकाचामरादिविरुदस्य प्रतिदिनप्रबन्धपरमेश्वरस्य भावनापुरुषोत्तमाद्यष्टादशरूपककर्तुः शतकन्धरविजयादिषष्टिकाव्यनिर्मातुः साहित्यसर्वस्वाद्यनेकालङ्कारग्रन्थप्रथयितुर्वेदान्तरत्नावलिवादतारावलिमध्वविडम्बन - बौद्धविध्वंसनमणिदर्पणाद्वैतकौस्तुभविधिनिर्णयसर्वमयसर्वस्वस्मृतिरत्नदीपिषष्टि - मङ्गव्याख्यानधातुपरिशुद्धितत्त्वावबोधाद्यनेकशास्त्रकरणविचक्षणस्य वापीकूप-

तद्राकारामाग्रहारप्रतिष्ठापकस्य रत्नखेटाद्दैताचार्यविश्वजिद्याजि श्रीनिवासयज्वनः पुत्रेण पातिव्रत्यादिसच्चरितनिरूढप्रसिद्धिकारुन्धत्याः कामाक्ष्या गर्भसंभवेन सर्वविद्याविशारदस्य श्रीकेशवयज्वनोऽनुजन्मना सर्वविद्यासाम्राज्याभिषिक्तस्य श्रीराजचूडामणेरग्रजनुषा पारिजातहरणसत्याभीनसाहित्यसर्वस्वाद्यनेककाव्यनाटकालङ्कारकर्त्रा विवरणसारनिबन्धनविधात्रा सकलशास्त्रपरिणिनार्धनारीश्वरभट्टेन विरचित समयमतसंजीविनामके अम्बास्तव व्याख्यानग्रन्थः संपूर्णः ।

(b) श्रीविद्याटीका

SRIVIDYATIKA.

Foll. 58a—85b. Extent, 615 Granthas.

This is a commentary on the Śrīvidyā, which is supposed to have been taught by Viṣṇu in the form of Hayagrīva. This Vidya is supposed to grant the reader all the four ends in view.

Beginning :

इहखलु भगवान् सर्वविद्यानिधिः बहुविधशाखामयर्ग्यजुस्सामवेद मूर्तिरपरिच्छिन्नचिच्छक्तिकलासमावेशतरङ्गितहृदयो हयग्रीवरूपी महाविष्णुः सकलज्ञानतपोनिधये परसच्चिदानन्दघनचिच्छक्तिरूपं पृष्टवते अगस्त्याय महामुनये अनेकविधशाखामयीनामृग्यजुस्सामशाखानामनेकविधासूपनिषत्सु तत्रतत्रविद्यमानरहस्यार्थावबोधस्य

* * * *

तत्तद्रहस्यार्थतत्त्वप्रकाशिनीं सकलपुरुषार्थसाधनत्वेनाभिमतां सकलपुरुषार्थप्रत्यक्षप्रकाशिनीं श्रीविद्यामुपदिशति । कए ईति । कनदीप्ताविति त्यस्माद्धातोः कन्यते प्रकाश्यतेऽनेन शब्दार्थजालानीति वा कनयतीतिवा ।

End :

इति संपूज्य यथाशक्ति मूलेन संपूज्य नमस्कारान्तं कृत्वा कल्याणवृष्टिस्तवेन देवीं स्मृत्वा यथासुखं विहरेत् ॥ श्रीराजराजेश्वर्यै नमः आवाहिता भव, स्थापिता भव, सन्निहिता भव, संनिरुद्धा भव, सुमुखी भव, अवकुण्ठिता भव, सकली भव, अमृती भव, प्रसीद नमः ॥

(c) श्रीचक्रप्रतिष्ठाविधिः
ŚRĪCAKRAPRATIṢṬHĀVIDHIḤ.

Foll. 86a—87b. Extent, 25 Granthas.

This work gives details regarding the consecration of the disc of Viṣṇu.

Complete.

Beginning :

अथैतत्प्रतिष्ठाविधिर्निरूप्यते

प्रकरणोक्ते शुभेदिने कृताह्निकस्साधकोगणपतिमाराध्य ब्राह्मणैः स्वस्ति वाचयित्वाचम्य प्राणानायम्य, देशकालौ सङ्कीर्त्यामुकगोत्रोऽमुकशर्मेवमीदिरदं श्रीललिताश्रीमहात्रिपुरसुन्दरीमाराधयिष्यन् श्रीचक्रराजप्रतिष्ठापनं करिष्य इति सङ्कल्प्य.

End :

चन्द्रचन्दनकस्तू[illegible]िकालागरुभिरुच्यते ।
अष्टाङ्गप्रणिपातस्तु वन्दनं कथितं प्रिये ॥
एतच्चराचरं सर्वं क्षेत्रमित्यभिधीयते ।
तत् क्षेत्रं पालितं येन क्षेत्रपालक उच्यते ॥

Colophon :


इति वै कथितं सर्वमूर्ध्वाम्नाय मुदीरितम् ।

(d) ललितास्तवरत्नम्
LALITĀSTAVARATNAM.

Foll. 94a—104b. Extent, 250 Granthas.

Same work as that described under D. No. 10827.

Complete.



MSS — Sanskrit